

४१०

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

ॐ नमः शिवाय ॐ श्रीगणेशाय नमः ॐ यस्तुष्टुवम
यामिन्द्रियगणश्चापागुश्च: सेहुत्यक्षयैवीनःम
स्रियेमामुज्याय मभावहरूटरुज्जालिअक्षिप्रैःअति
संयुतैः मधुरूभमृत्येवनैन्यालिखमासाम
भयसैउपठलेनभाजमदाम्बक्रइमित्र श्रीयंसंमकं
हुयंउह्रिमेपविणःक्रामित्र ठागत्प्रायाहृन्द्रैवकं
मधैनमक्षव: रुप्तैहुतित्रलिक्षसामक्रांकमाप्तु
स्त्रिलिकूंरुश्रितियंभिप्तुरेउस्ययैमिति सिमिद्धुलिकं
मेमङ्कृत्युणाणितप्रचठकु ॥ मवृष्टयंश्रुतनाक
शिक्विवृद्धिमालया: मुमलैकैहुतिकिंवड्रीशुयांली
वृद्विविमुपमा मममश्रिसलगाद्वशामिदमाचिवृकःस्र
गः मपचाल:भमश्रमभिमिविवैमामितिम्रोकुमः श्रुति
इयामिविमदलोणामाणिरिवद्रुना: श्रुतिहृतकवेद्र
प्रापृराहृत्मुमहगतु: बहिद्याणा:हृतुगामीवाणः
पुकृपत्रयः कपंकर्दैवरूपाणिसिकाल्वेतपृ निं॥

सुरूः हविश्ववसवगुणिग्रहप्रवानिलाः भगवालोकगा

ग्राह्णयह्यन्नारायणदेवः विष्णुरयौवनयशोदाराम

किन्नरः पितामहोग्रहरूकः विद्युत्कुंडलीकृद्विवर्णायः ॥

पद्मनाभः हृषीकेशः पद्मनाभो विश्वरूपवान् सुसिधूकिरीट

डः प्रवरेश्वः सर्वज्ञः सर्वलोकप्रभुर्गुणप्रवालश्च

गाडः भामन्दहृष्टनवाभ्रमत्क्रीककालिकः मदहि

दमवल्लभयवालीविनायकः भरीदः मीधरः माधु

धनिः माकृश्यनिमुखः भमाकृभिदः भवाक्रसिद्धः मोदु

दविश्रमः गोत्रमङ्गलकुवड्ड्वमायाविवीश्चसुमः ॥

वदमूढः परमेश्वः परमश्री पितामहः जिनहृदयलोके

मः प्रवयखुलडगानः डडानयोविद्युजिल्विविष्ठिः कन

लामनः भध्रुपश्वलपाडि वैणविणडविश्वरूपस्तुतिः मड

नदः मडपतिः कुवियदेवनन्दनः विष्णुप्रायपदः

धुवैकुण्ठो विष्णुरमूवाः हषीकेशः हृषीकेशः केशवो माधवः

मुकुः हरिः पुण्डरीकाक्षो विष्णुतादरदुलः पीतभु

हृदः साक्षीविश्वक्सेनो जनार्दनः उपेन्द्रो वरश्च

कपालिस्ववहुणः पद्मनाभ भवविभवाधवविष्णुः

भः देवकीनन्दनः मौरिः श्रीपतिः पुरुषोत्तमः वनमाली

बलिध्वंसी कंसारातिरधोक्षजः विश्वम्भरः कैटभजिद्वि
धुः श्रीवत्सलाञ्छनः। पुराणपुरुषोत्तमायी ना
रायणः॥ वसुदेवोस्य जनकः आनकदुन्दुभिः॥ बलभद्रः
प्रलम्बघ्नो बलदेवोऽच्युताग्रजः रेवतीरमणो रामः कामपा
लो हलायुधः नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली
सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः॥ मदनो मन्म
थो मारः प्रद्युम्नो मीनकेतनः कन्दर्पो दर्पकोऽनङ्गः कामः पञ्च
शरः स्मरः शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः पुष्प
धन्वा रतिपतिर्मकरध्वज आत्मभूः। ब्रह्मसूर्विश्वकेतुः स्यादनि
रुद्ध उषापतिः॥ लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रि
या क्षीरसमुद्भवा भद्रेन्दिरा लोकजननी रमा॥ शङ्खो ल
क्ष्मीपतेः पाञ्चजन्यः चक्रं सुदर्शनः कौमोदकी गदा खड्गो नन्
दकः कौस्तुभो मणिः॥ गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगे
श्वरः नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः॥ शम्भु
रीशः पशुपतिः शिवः शूली महेश्वरः ईश्वरः सर्व ईशा
नः शङ्करश्चन्द्रशेखरः भूतेशः खण्डपरशुर्गिरीशो गिरि
शो मृडः मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः उग्रः
कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् वामदेवो महा

र्वो विरूपाक्षस्त्रिलोचनः कृशानुरेताः सर्वज्ञो धूर्जटि
र्नीललोहितः हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः
गङ्गाधरोन्धकरिपुः क्रतुध्वंसी वृषध्वजः व्योमकेशो भवो भीमः
स्थाणू रुद्र उमापतिः अहिर्बुध्न्योष्टमूर्त्तिश्च गजारिश्च महा
कपिः भैरवः शिपिविष्टश्च गङ्गाधरजटाधरः ॥ कप
र्दोस्य जटाजूटः पिनाकोजगवं धनुः प्रमथाः स्युः पारिष
दा ब्राह्मीत्याद्यास्तु मातरः विभूतिर्भूतिरैश्वर्यमणिमादिक
मष्टधा ॥ उमा कात्यायनी गौरी काली हैमवतीश्वरी शिवा
भवानी रुद्राणी शर्वाणी सर्वमङ्गला अपर्णा पार्वती दुर्गा
मृडानी चण्डिकाम्बिका आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा
चामुण्डा चर्चिका चैव चर्ममुण्डा कुलनायका ॥ विनाय
को विघ्नराजद्वैमातुरगणाधिपाः अप्येकदन्तहेरम्बलम्बो
दरगजाननाः ॥ कार्त्तिकेयो महासेनः शरजन्मा षडाननः
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः बाहुलेयस्ता
रकजिद्विशाखः शिखिवाहनः षाण्मातुरः शक्तिधरः कु
मारः क्रौञ्चदारणः ॥ इन्द्रो मरुत्वान्मघवा बिडौजाः पाक
शासनः वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः जि
ष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः

5

दुष्पर्णीवासकेविरुद्धदन्धा वाम्भेष्मतिः शवपत्रिद्रुला
नत्तिःसमीपत्तिः एम्भकेमीदगिदयःश्रावणश्रवमि
श्रमरः श्रुवापन्नलःअदमाकण्डुकाञ्चमूडुखिया।
पल्लीमरकसमीद्रुम्लीगवारीद्रुमगंवडी॥दयाउस्नैःसुवः॥
श्रुद्धभाउल्लिद्रुकर्णवरभा॥श्रुाद्भुभाक्रिवोल्यद्भुएायउः।
पाकसामनिः॥विगवडेद्रुभाउद्भिगुवश्रृद्रुभवल्लकः॥
हरिद्रीवल्लभधृशीभृद्भुल्लिमंठिद्दरंपविः।मडकीटिः।
श्रुमःसभ्लुल्लिरसनिद्भुयैः॥द्भुमयगंविभार्गद्धीगयमद्भुः।
भरद्घयः॥भृद्रुणमदवमकपीग्रयभभाउद्भुण।भङ्
कीनीवियद्रमद्रुगृहसीभरमीन्निक॥भेकःश्रुभेकःजि
भार्ङ्गीरद्रभाद्रःसगालयः॥पंस्नैउमवउरवेभकवः।
पाविरउकः।मञ्जरःकल्कबकद्भुशंभिवादविमद्भ
नभा॥भनक्रुभाविवणद्रुःश्रुवैस्ववृश्रिनीभद्धो।गभसा।
वाश्विनीदभावाश्चिनैयोमञ्जवठे॥भियांगफश्रुभद्भर
भःश्रुवेमृउवमीभाापाः॥ददक्रुक्रुश्नैवभाहगाद्भु
वाश्रुद्धिवोकभाभा॥ पग्रिवैश्रागेवक्रिवीडिक्क
द्रुणज्ञयः नघीलयेविल्लुलनैरउवेमनुग्रनभाउ
वडिःश्रुभ्राणक्रुवद्भुरेगमिद्भुमउयञ्चणः श्रमयामिव

द्भानुः कृशानुः पावकोऽनलः रोहिताश्वो वायुसखः शि
खावानाशुशुक्षणिः हिरण्यरेता हुतभुग्दहनो हव्यवाहनः
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः शुचिरप्पित्तमौर्व,
स्तु वाडवो वडवानलः। वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शि
खा स्त्रियाम्। त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥
धर्मराजः पितृपतिः समवर्ती परेतराट्। कृतान्तो यमुनाभ्राता,
शमनो यमराड्यमः कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः
मृत्युधिपः पाप्मदमः कीनाशो मृत्युरन्तकः ॥ राक्षसः कौण
पः क्रव्यात्क्रव्यादोऽस्रप आशरः रात्रिंचरो रात्रिचरः कर्बुरो निक
षात्मजः यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ प्रचेता,
वरुणः पाशी यादसांपतिरप्पतिः ॥ श्वसनः स्पर्शनो वा
युर्मातरिश्वा सदागतिः पृषदश्वो गन्धवहो गन्धवाहानिला,
शुगाः समीरमारुतमरुज्जगत्प्राणसमीरणाः नभस्व
द्वातपवनपवमानप्रभञ्जनाः ॥ प्रकम्पनो महावीरो रंहस्तु,
कृष्णाङ्गुलिभस्त्रा, प्राणापानसमानोदानव्यानाः पञ्चवाय
वः हृदयनाभिकण्ठगुदसर्वाङ्गगाः क्रमात्। शरीरस्थ,
वेगनामानि रंहोऽत्यन्तवेगः
पृ॰ इमे रंहस्तरसी तु रयः स्यदः, एवं जवोऽथ शीघ्रं त्वरितं लघु,
के॰ क्षिप्रमरं द्रुतम्। सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥
३

सङ्ग्रामाय शस्त्रास्त्र सङ्ग्राविरङ्गाविसभम् । विष्टब्ध रङ्गाए

सभग्नप्राग्निसयेन्द्रः पङ्क्तिलक्ष्माष्टजङ्गिभाङ्गिन्द्रतः ।

निष्ठरभम् ॥ डीविकुशुविङगुवि ॥ गाण्ड गाण्ड ष्ठवभिम ॥

क्लीवसीभूष्टसङ्घभूष्टिषुभिमृष्टिगाभियड ॥ कवे

रसूभ्रकमायेयकराङ्कहृत्केशरः । मजवृणमणवर्गे । रा

णवाणिवणियः किवरसेविसवलः पोलवृष्टिवधाज

नः यक्षैकुपिङ्गिविदमीयित्रपुगलेश्वरः ॥ वृष्टिहरं ।

सैहुगं घः प्रदसुरहक्रावरः । कैलासः कुरभूलकप्र ॥

विभावं कुपश्लकम् । शूक्तिवरः किम्बदमयुवक्षवद

रभयः । विणिङ्गसैवणिद्धिः सन्धपद्मस्पर्याविणः ॥ भज

पद्मत्रपद्मत्रसन्तिमकवकस्थपी भजकज्ञमीलाब्र ।

पिवङ्ग्रणियेव ॥ ११ ॥ ॐ हमवर्णिङविरमितं

नामलिङ्गत्रमामनेश्वरन्दिकस्त्रवत्तनः प्रथमः ॥ ॥

हृष्टिविवृष्टियाभहृष्टिमयक्षसभग्रमम् । नक्तिरुविकङ्गव

नभगवुंशवबद्धपम् । वियङ्किविष्टपदंगिपिधंप्रभूतकमवि

नयसी ज्ञापयद्भसेव्यायुसङ्गविलक्षिदिरमृतम् । ॥

ऊिमपुकरः कथुणुमाव्रजरियद्रः प्रभृत्वमीर

तीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ उत्तरादिगुदीची स्याद्दिश्यं
तु त्रिषु दिग्भवे ॥ इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्
कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ ऐरावतः पु
ण्डरीको वामनः कुमुदोऽञ्जनः पुष्पदन्तः सार्वभौमः सुप्र
तीकश्च दिग्गजाः क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रि
याम् ॥ अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् ॥ अभ्रं मे
घो वारिवाहः स्तनयित्नुर्बलाहकः धाराधरो जलधरस्त
डित्वान्वारिदोऽम्बुभृत् घनजीमूतमुदिरजलमुग्धूमयो
नयः ॥ कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् ॥ स्त
नितं गर्जितं मेघनिर्घोषे रसितादि च ॥ शम्पाशतह्रदा
ह्रादिन्यैरावत्यः क्षणप्रभा तडित्सौदामिनी विद्युच्चञ्चला चप
ला अपि ॥ स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः ॥
इन्द्रायुधं शक्रधनुस्तदेवर्जुरोहितम् ॥ वृष्टिर्वर्षं तद्वि
घातेऽवग्राहावग्रहौ समौ ॥ धारासम्पात आसारः शीकरोऽम्बुक
णाः स्मृताः ॥ वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् ॥
पु० अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् । अपिधानतिरोधा
कि० ८ नपिधानाच्छादनानि च ॥ हिमांशुश्चन्द्रमाश्चन्द्रः

बान्धवः। विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः।
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः। द्विजरा
जः शशधरो नक्षत्रेशः क्षपाकरः। [illegible]
[illegible] कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं
त्रिषु। भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौ
मुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता। कलङ्काङ्कौ लाञ्छनं च चिह्नं
लक्ष्म च लक्षणम्। सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छ
विः। अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्। प्रालेयं
मिहिका चाथ हिमानी हिमसंहतिः। शीतं गुणे तद्वदर्थाः
सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्ता
न्यलिङ्गकाः। ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः।
मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी। नक्षत्रमृक्षं
भं तारा तारकाप्युडु वा स्त्रियाम्। दाक्षायिण्योऽश्विनीत्यादि तारा अश्व
युगश्विनी। राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया
समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः। मृगशीर्षं मृ
गशिरस्तस्मिन्नेवाग्रहायणी। इल्वलास्तच्छिरोदेशे तारका
निवसन्ति याः। बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः।

गुरुः ‖ जीवाङ्गिरसवाचस्पतिश्चित्रशिखण्डिजः ‖ शुक्रो
दैत्यगुरुः काव्य उशना भार्गवः कविः ‖ अङ्गारकः कुजो भौमो
लोहिताङ्गो महीसुतः ‖ रौहिणेयो बुधः सौम्यः ‖ समौ सौरश
नैश्चरौ ‖ [illegible] ‖ तमस्तु
राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ‖ सप्तर्षयो मरीच्यत्रिप
प्रमुखाश्चित्रशिखण्डिनः ‖ राशीनामुदयो लग्नं ते तु मेषवृषाद
यः ‖ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः भास्कराह
स्करब्रध्नप्रभाकरविभाकराः भास्वद्विवस्वत्सप्ताश्वहरिद
श्वोष्णरश्मयः ‖ विकर्त्तनार्कमार्त्तण्डमिहिरारुणपूषणः ‖
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ‖ विभावसुर्ग्रह
पतिस्त्विषाम्पतिरहस्पतिः ‖ भानुर्हंसः सहस्रांशुस्तपनः स
विता रविः ‖ कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ‖
प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ‖ इनो भगो धाम
निधिः चांशुमाल्यब्जिनीपतिः ‖ माठरः पिङ्गलो दण्डश्चण्डांशोः
पारिपार्श्वकः ‖ सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ‖
परिवेषस्तु परिधिरुपसूर्यकमण्डले ‖ किरणोऽस्रमयूखांशु
गभस्तिघृणिधृष्णयः ‖ भानुः करो मरीचिः स्त्रीपुंसयो

[illegible]

पृ. के. ५

दीधितिः स्त्रियाम् ॥ स्युः प्रभा रुग् रुचिस्त्विड्भाभाश्छविद्युति
दीप्तयः । रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ कोष्णं
कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ॥ तिग्मं तीक्ष्णं खरं तद्व
न्मृगतृष्णा मरीचिका ॥ ३३ [illegible]
[illegible] ३ ॥ कालो दिष्टोप्यनेहापि समयोप्यथ पक्ष
तिः । प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ घस्रो दि
नाहनी वा तु क्लीबे दिवसवासरौ ॥ प्रत्यूषोहर्मुखं कल्यमु
षः प्रत्युषसी अपि प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः ॥
प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी निशा निशीथि
नी रात्रिस्त्रियामा क्षणदा क्षपा विभावरी तमस्विन्यौ रजनी
यामिनी तमी तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता ।
आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी ॥ गणरात्रं निशा
बह्व्यः ॥ प्रदोषो रजनीमुखम् ॥ अर्धरात्रनिशीथौ द्वौ ॥ द्वौ याम
प्रहरौ समौ । स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम्
पक्षान्तौ पञ्चदश्यौ द्वे ॥ पौर्णमासी तु पूर्णिमा ॥ कलाहीने
सानुमतिः पूर्णे राका निशाकरे ॥ अमावास्या त्वमावस्या ।
दर्शः सूर्येन्दुसङ्गमः ॥ सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुक

लाङ्गूलः । उपाकृतः [illegible] प्रोक्षितम् । मेध
[illegible] । [illegible]
[illegible] । [illegible] ॥
[illegible] । [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible] । [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] । [illegible]
[illegible] ॥ [illegible]
[illegible] । [illegible]
[illegible] । [illegible]
[illegible] । [illegible]
[illegible] । [illegible] ।

संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ मासेन स्यादहोरात्रः
पैत्रो वर्षेण दैवतः ॥ दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृ
णाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ संवर्तः प्र
लयः कल्पः क्षयः कल्पान्त इत्यपि ॥ अस्त्री पङ्कं पुमान्पाप्मा
पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोऽघमंहो दुरितदुष्
कृतम् ॥ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ॥ मुत्
प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः । स्यादानन्दथुरानन्दः ।
शर्मशातसुखानि च ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं ।
शुभम् । भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं
चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ मतल्लिका मचर्चिका ।
प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमून्ययः शुभावहो वि
धिः ॥ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ॥ हेतुर्ना का
रणं बीजं निदानं त्वादिकारणम् । क्षेत्रज्ञ आत्मा पुरुषः प्रधा
नं प्रकृतिः स्त्रियाम् । विशेषः कालिकोऽवस्था गुणाः सत्त्वं र
जस्तमः ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः । प्राणी तु
चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ जातिर्जातं च सामान्यं
व्यक्तिस्तु पृथगात्मता ॥ ३० इत्यमरकोषे प्रथमकाण्डे कालवर्गः । ४ ॥

१४

वद्धिदनीधाविमप्रणीः पृछमेमथीमडिः पूर्छ्येपुलद्वि
ज्ञिद्धं विद्धडिपद्धुभ्रिमेडाः णीकाव्रव्रवडीमणंमकल्दः
कमभानमभा। मिडुकिणेभनभ्रुवद्धवामछुविमावप्र।
पहणदवभुकऊकेविमिकिमडुमंमयः मकिदडूथवि
माघमभोनिलपनिद्भुयो। मिघादुघ्रद्रभ्रिकडाहूथाद।
दूदमिडुनभ। मभोमिद्धडाडुडाहुडिमिघुमभडिदु
मः मंविद्धः धुडिह्लवंनियभामुवमंमवाः पद्मी
काहुपुगमधुडिमवमभाथ्यः मेकिणीलुंनभुटर।
विद्ध्वंमिलदमाभूयिः मुक्तिः कृवलुविवाम्ममूयि।
निः मूयमाभडभं। मेकोपवलेमाडुनभुविहुद्धमडिः
भियामा। कृपंमर्कणाडुनभभवामद्धविमयाधुभी। गो
मवाडङ्किपाऊद्धहपीकंविमयीभ्रियम। कदेम्भूयं
डुपाधाभ्रिमेवेइकिणीभ्रियम। डंवनमुकथायेभ्री
मघविलवलः कदुः डिडिभ्रुमवभाः धुमिडङ्गहमद
भीदिम। विमद्धङ्कपविमलेगहुलनभवेदव। ड्रमे
दः मेडिनिदगेवाघ्रलिद्धकभाग्रुप्रडा। मुभाकद्दीडुमिद
गीभवकिडुल्लडयलः उग्नूगहः भगाविः भूदभलीभाप

वासनः ॥ पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् ॥ शुक्ल
शुभ्रशुचिश्वेतविशदश्येतपाण्डुराः ॥ अवदातः सितो गौरो व
लक्षो धवलोऽर्जुनः ॥ कृष्णे नीलासितश्यामकालश्यामलमेच
कः ॥ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ लोहितो
रोहितो रक्तः शोणः कोकनदच्छविः ॥ अव्यक्तरागस्त्वरुणः श्वे
तरक्तस्तु पाटलः ॥ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहि
ते ॥ कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ चित्रं कि
र्मीरकल्माषशबलैताश्च कर्बुरे ॥ गुणे शुक्लादयः पुंसि गुणि
लिङ्गास्तु तद्वति ॥ ०१ ॥ इत्यमरकोशे स्वर्गादिकाण्डे
धीवर्गः ५ ॥ ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्व
ती ॥ व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ अपभ्रंशोऽपश
ब्दः स्याच्छास्त्रे शब्दस्तु वाचकः ॥ तिङ्सुबन्तचयो वाक्यं क्रिया
वा कारकान्विता ॥ श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्वि
धिः ॥ स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ शिक्षेत्यादि श्रुतेरङ्ग
मोंकारप्रणवौ समौ ॥ इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वरा
मुदात्ताद्याः स्वराः ॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्र
योः ॥ आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ प्रब

मुकल्दनाकथाश्च प्रवल्हिका प्रहेलिका॥ स्मृतिस्तु धर्मसंहि-
ता समाहृतिस्तु संग्रहः॥ समस्या तु समासार्था किंवदन्ती ज-
नश्रुतिः॥ वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥ आख्याह्वे
अभिधानं च नामधेयं च नाम च॥ हूतिराकारणाह्वानं संहूतिर्बहु-
भिः कृता॥ विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्॥ उपो-
द्घात उदाहारः शपनं शपथः पुमान्॥ प्रश्नोऽनुयोगः पृच्छा च प्र-
तिवाक्योत्तरे समे॥ मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्॥
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः॥ यशः कीर्तिः स-
मज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥ आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं
तु घोषणा॥ काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥
अवर्णाक्षेपनिर्वादपरीवादापवादवत्॥ उपक्रोशो जुगु-
प्सा च कुत्सा निन्दा च गर्हणे॥ पारुष्यमतिवादः स्याद्भर्त्सनं त्व-
पकारगीः॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्॥
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति॥ स्यादाभाषणमाला-
पः प्रलापोऽनर्थकं वचः॥ अनुलापो मुहुर्भाषा विलापः परि-
देवनम्॥ विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥ सु-
प्रलापः सुवचनमपलापस्तु निह्नवः॥ संदेशवाग्वाचिकं

[illegible]

[illegible]

मृगाङ्कभुषि वसन्ते कथं वाङ्कल्पानी मृगाङ्कतुल्यं कुसुमचन्द्रि

का पुष्पमञ्जरी आम्रं अङ्कुर क्रमयत् भ्रमर। निपीय मधु

मल्लीलताकुञ्जे प्रिये मदमत्त कोकिलविहंग मन्दपवनाद्

लतावलयपङ्क्ति भुवि मञ्जरी विकसितं भ्रम। पुष्पवनं भवि श्रीव

मकरन्द मृगनयनक भ्रम। वसन्तव भवानी मृगाङ्कदं कुसुमवनकम।

मधुलिह भुवि मन्द विडम्बित वनः। मल्लिका कुसुम

लतिका कलिकाशिखभ्रम। मञ्जुरवं मधुपानविहित विहङ्ग

मन्द निनाद वितत विकसित रवमत्ताः। प्रागविह्गविहंग

दधि मधुर विभ्रमाः श्रवणरवमञ्जरी विरवा पवन मन्दः मधु

निकुञ्ज पल्लवाङ्कुर मञ्जरी भ्रमर। निकुञ्ज विकुञ्जः कु

ञ्जः कुञ्जः कुञ्जनभिरूपि वीणयाः कूजितैः मधुरैः मृदङ्ग

मधुप्रमदयः कोकिलाकुलः कलकलभिरवम्भविनिर्मित भ्रम।

मीमृदङ्गमृदुगिरं संगीतगानं विभिम्रम ॥ ३१ ॥ इति श्री

कविमथानिकविकल्पमहाकविवनः १ ॥ ॐ नमोऽस्तु देवान्य

रथकम्पमर्मवः मङ्गलमङ्गलश्रीमधुरश्रीकण्ठकिरीटः प्रभुः।

कङ्कलीकुलकलप्रभावलीविभव मन्दारकल्पभूमण्डल श्रीर।

डमरुडिण्डिमभूषित मधुरिपुकुलालय मृदुकुलाधीश वल्लकी।

विपञ्ची मातृकाशीलिः मञ्जुलिः परिवादिनी डिण्डिमश्रीकिंकिणी

[illegible]

[illegible]

[illegible]

उपाति[illegible] शुभि[illegible]भीरूपा॥ [illegible]

[illegible]कुलिके समं॥ उ[illegible]देरूवभाय[illegible] [illegible] कय

[illegible] पुण्यम[illegible]कैउवे॥ [illegible]

[illegible]दलम। कैशु[illegible]कं[illegible]वण[illegible]॥ [illegible] विला

[illegible]किविरु[illegible] लिउउ[illegible] देलालीलिरूभीद[illegible]

[illegible]: [illegible]:कीलिप[illegible]लीलाम[illegible] [illegible]

[illegible]पिलाम[illegible]दम। [illegible]

लयो[illegible] [illegible] [illegible]

[illegible]

[illegible]दलम। [illegible]

लम। विश्व[illegible]विमं[illegible]लनेसमं॥ [illegible]

[illegible] [illegible]भीला[illegible]

[illegible]याम। [illegible]

[illegible]

उद्भवः ॥ [illegible]: ॥ १ ॥ [illegible]

वलि[illegible]म। [illegible]

लम। किं[illegible] [illegible]

सहेश्वरक्तुषधिर्वंशिष ॥ पृथुकरी स्त्रियं प्राङ्गं उमिथुङ्गिमिरंडमः ॥
स्वते गण्डितुत्ङमभक्रीलिक्सुरमंडमः ॥ विश्वक्रान्तमभंगणाङ्कपृ
वैयाघ्रमीश्वरः मैधिरुकुवाश्रकिंशुमध्रवाणीवृगेनमे ॥ ङिलक्ष्म
मृद्गणवारेश्वयवोदभुडस्कृति ॥ वलगङ्गणलष्टालस्मभोग
लिलस्पृक्तो ॥ भालणीभाङ्लादिविद्रूतभक्रकस्नुकः ॥
मधश्मज्ञकुलणीकुलस्तीदिक्कुलस्मः ॥ पृमीविधेविशद
गस्वक्नीष्टालस्मरीमथः ॥ क्रस्लीकुष्ठपास्वकश्वधक्क
केमवडैली ॥ मवीकरीत्रीक्रपश्चुदृमस्तकेतिलमयः ॥ उर
गधैत्रगोठैगीलिक्रणपैत्रगामरः ॥ क्रश्रीवमेलेलिदर ॥
क्ष्मुकीगल्मथकः ॥ दिव्यादेयंविधाक्रम्लिष्ठस्यांतुछ
श्रद्वयेः ॥ ममीकल्कुकनिम्निकोष्टुदमुगवल्लंविमम ॥ भंसि
क्रीधमक्काकैलकलक्रिएकलादलाः ॥ मौगधूकश्रेष्टु
केयेवम्मवेरुदीधरः ॥ लदैवस्नाकस्वविधछदपमीरव ॥
विधवैहटैस्कुलिकैष्टल्लणाहृदिक्रुस्कः ॥ धाडलकोगि
वनो ॥ ३ ॥ विष्णुाक्रावकमुत्रवकोविरयेदेनडिभि
याम ॥ इक्षुदस्युपणावीमिमदरीवयवेरवाः ॥ मंदक्रल
श्रंङ्मष्टटाभदस्त्रमुरावकाः ॥ पेङ्कवैतरलीमिवुस्पृदल ॥

श्रीभुक्तिवृत्तिः ॥ विधुरमणुक्तारम्रञ्जुयाज्याङीवृवमृता ॥ पीन्
वाणम्रवाङ्ग्व भाष्यरशुंभू प्रडिलप ॥ श्रान्तभुक्तभाकीनं ॥
शिशिरांशुकिरणगाभिरः ॥ मकरन्दः ७ ॥ [illegible]
[illegible]वाफीरावारम्भरिद्धतिः ॥ उमदन्नारमणिश्चि
वृन्दरभाङ्गगारैलुवः ॥ रङ्गकरेलनतिथिःयामपीडिरूपां
पतिः नमीनाम्बिवारिधूरेवीमिमालीकयवसुप्रः ॥ उर्श्रृङ्गदः
श्रीरमृदुलवल्लिमभुषापर ॥ प्रयः श्रीकृष्णश्रिवाकारिमलिलं
कमलं[illegible]लभ ॥ पयस्त्रीलालभम्डंलीवरंगुवरंवरणे ॥
कवरूपमकंपाघपैश्करंभवडेभापभ ॥ पश्चिलश्चेयपानी
यसीरश्रीरभूमभूरं ॥ भिष्यपुष्पपरमहिमश्रिगुध्रम्भयम ॥
ठकभुरक्रुडुमिश्चाभ्रियांवीमिरमृबक्रिम मञ्जुल्लीलकल्ली
लीभूपायरेडेम्भंड्रमः ॥ पक्षत्रिविश्वपक्षदः भूभां सेविश्वू
मधुपः ॥ मेंकुलिपृएर्टमश्रुश्रुभांस्वल्लरिनभाः ॥ श्रीलं
रेणुश्रीरमधुश्रीरमडयभिध ॥ पापरारैपायरामीशीरपा
ईडरमडरभ ॥ श्रीपाभिमुधामुडीपंडमडचारिलिम्भुपमे ॥
डेयोग्निडंडध्रुलिरंमिकडभिकडभयभ ॥ निमक्वरमुणध्व
लपीकश्रीमादकरमो ॥ एलीक्षुभापीवीवादक्षुपकम्

विदारकाः॥ नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥ उडु
पं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः॥ आतरस्तरपण्यं स्याद्द्रोणी
काष्ठाम्बुवाहिनी॥ सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः॥
नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥ नौकादण्डः क्षेपणी
स्यादरित्रं केनिपातकः॥ अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु से
चनम्॥ यानपात्रं तु पोतो वहित्रं [illegible]॥ नावादिके [illegible]
[illegible] द्विकं॥ क्लीबेऽर्द्धनावं नावोऽर्द्धेऽतीतनौकेऽति
नु त्रिषु॥ त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥ निम्नं गभीरं [illegible]
गम्भीरमुत्तानं तद्विपर्यये॥ अगाधमतलस्पर्शे कैवर्त्ते दाशधी
वरौ॥ मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम्॥ पृथुरोमा
झषो मत्स्यो मीनो वैसारिणोऽण्डजः॥ विसारः शकली चाथ गडकः श
कुलार्भकः॥ सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ॥
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः॥ क्षुद्राण्डमत्स्य
सङ्घातः पोताधानमथो झषाः॥ रोहितो मद्गुरः शालो राजीवः शकु
लस्तिमिः॥ तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः॥
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥ स्यात्कुलीरः कर्कटकः
कूर्मे कमठकच्छपौ॥ ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

गण्डूपदः किञ्चुलको निहाका गोधिका समे। रक्तपा तु जलौका-
यां स्त्रियां भूम्नि जलौकसः। मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्या-
त्कम्बुरस्त्रियाम्। क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलशुक्तयः।
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। शिली गण्डूपदी भे-
की वर्षाभ्वी कमठी डुलिः। मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घ-
कोशिका। जलाशया जलाधारास्तत्रागाधजलो ह्रदः। आहा-
वस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपा-
नं तु पुंसि वा। नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्। पुष्करि-
ण्यां तु खातं स्यादखातं देवखातकम्। पद्माकरस्तडागोऽस्त्री का-
सारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका।
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्। स्यादालवालमा-
वालमावापोऽथ नदी सरित्। तरङ्गिणी शैवलिनी तटिनी ह्रा-
दिनी धुनी। स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा। कूलंकषा
निर्झरिणी रोधोवक्रा सरस्वती। गङ्गा विष्णुपदी जह्नुतनया सु-
रनिम्नगा। भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि। कालिन्दी
सूर्यतनया यमुना शमनस्वसा। रेवा तु नर्मदा सोमोद्भवा मेक-
लकन्यका। करतोया सदानीरा बाहुदा सैतवाहिनी। शतद्रु

दा सैतवाहिनी । शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु वि
पाट्स्त्रियाम् । शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् । शराव
ती वेत्रवती चन्द्रभागा सरस्वती । कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसं
गमः । द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ । देविकायां सर
य्वां च भवे दाविकसारवे । सौगन्धिकं तु कह्लारं हल्लकं रक्तसन्ध्य
कम् । स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नी
लेऽस्मिन्सितं कुमुदकैरवे । शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुं
भिका । जलनीली तु शैवालं शैवलोऽथ कुमुद्वती । कुमुदिन्यां नलि
न्यां तु बिसिनी पद्मिनीमुखाः । वा पुंसि पद्मं नलिनमरविन्दं महोत्प
लम् । सहस्रपत्रं कमलं शतपत्रं कुशेशयम् । पङ्केरुहं तामर
सं सारसं सरसीरुहम् । बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ॥
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे । रक्तोत्पलं कोकनदं नाल
नालमथास्त्रियाम् । मृणालं बिसमब्जादिकदम्बे षण्डम
स्त्रियाम् । करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् । संव
र्तिका नवदलं बीजकोशो वराटकः ॥ वारिवर्गः १० ॥
उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् । पातालभोगिनर
कं वारि चैषां च संगतम् ॥ इत्यमरसिंहकृते स्वर्गादिकाण्डः प्रथमः ॥ १ ॥

दिमवादिमक्रन्मन्निवेष्टमिकरत्नरे नीलन्नियुग्मस्त्रीवान्मुमनोनुभावनः ॥ दिमवक्तितुपेरनुदमृत्त्रिमनावपि
स्दणिवरयागाष्मनष्टमिनःस्वकीतिः मुमनमृत्युवैप्रचाममनमुद्भुपन्निमार उयेवेयानुवंसिदेनदवदं विदस्तणः

ष्ठिवनायजीवकक्षीरकृष्णोषधिमवादिभिः टश्रक्रमाइवि
कुर्दैःमात्मपात्मैविदैःडिसः ॥ ष्ठिक्षुकुमिरयलानुजाग्भावि
ष्वमनाक्तिरा वयाणविशीवलिः क्रिणीस्तकसूपीजिडिः
मवंभदवमभज्ञीवमणेवीवमनुरा गैस्राक्रमपैविवीप्यस्त्रीम्म
वर्विमैष्मिरीमदी क्षुद्रकर्मीरद्रुगन्धविपलाभागयाम्प्रुरा वरा
हवक्षीविलाक्रमापिपविकीद्रिड ॥ मन्त्रुडिकपूमनुरुम्ब्रह्म
मन्त्रुभूपडिक ॥ उवरामवममूपाक्हृत्रागुपः क्षयमडिका ॥
उपवात्रपवीत्रुवपृष्टुलिन्दैभूलंकुली ॥ ममभोमकणवागेइ
पिलापुवदङ्मम ॥ हिमुतेणवाउलिकेविमपंकुवरणवाउ ॥
लिकेपंकरउवरं ममयवष्टमनुयैवतिः डमभ्रुणमाक्रिमन्नीमू ॥
दृष्मीमूपन्निभिदुरा ॥ प्रस्ति(?)क्रतिमषाक्रहृष्टतिमभुमहपमःपुह
वद्दैस्टक्रमिःमष्टंविष्टुजिमालयैः शीक्षणायमडक्रमविष
योक्षुपवदग्रम ॥ हिमुणिभुगदयैयिनदुत्रदुलडष्टपि ॥ क्रम
द्वत्रुभमहमुपयेवेदमात्रदवद्भमे ॥ माडलस्नापदविडमणापु
लिङ्गपक्तिलः एणलपुषयमडयंपुष्टसिकक्रमपावियः ॥
भूमिकगमकविलस्त्रुफरक्रकपवडि ॥ डमेलयामिभाविद्र
भद्रयीमिकडावडि ॥ डमेरहपुप्यमूभूमभदवझीदियालिडः ॥

स्यान्नदीमातृकोदेवमातृकश्चयथाक्रमम् । सुराज्ञिदेशे
राजन्वान्स्यात्ततोऽन्यत्रराजवान् । गोष्ठंगोस्थानकंतत्तुगौष्ठीनंभूत
पूर्वकम् । पर्यन्तभूःपरिसरःसेतुरालिःस्त्रियांपुमान् ॥
वामलूरश्चनाकुश्चवल्मीकंपुंनपुंसकम् । अयनंवर्त्ममा
र्गाध्वपन्थानःपदवीसृतिः । सरणिःपद्धतिःपद्यावर्तन्येकपदी
तिच ॥ अतिपन्थाःसुपन्थाश्चसत्पथश्चार्चितेऽध्वनि । व्यध्वोदुर
ध्वोविपथःकदध्वाकापथःसमाः । अपन्थास्त्वपथंतुल्ये
शृङ्गाटकचतुष्पथे । प्रान्तरंदूरशून्योऽध्वाकान्तारंवर्त्मदुर्गमम् । गव्यूतिः
स्त्रीक्रोशयुगंनल्वःकिष्कुचतुःशतम् । घण्टापथःसंसरणं
तत्पुरस्योपनिष्करम् । द्यावापृथिव्यौरोदस्यौद्यावाभूमीचरोदसी ।
दिवस्पृथिव्यौगञ्जातुरुमास्याल्लवणाकरः ॥ भूवर्गः ॥
पूःस्त्रीपुरीनगर्यौवापत्तनंपुटभेदनम् । स्थानीयंनिगमोऽन्यत्तु
यन्मूलनगरात्पुरम् । तच्छाखानगरंवेशोवेश्याजनसमाश्रयः ।
आपणस्तुनिषद्यायांविपणिःपण्यवीथिका । रथ्याप्रतोलीविशिखा
स्याच्चयोवप्रमस्त्रियाम् । प्राकारोवरणःसालःप्राचीनं

यितृपि ॥ भूम्लीशिखंकाम पर्णा ॥ कडुम्काडुम्वहृपि । कृपचतु ।

निषहायां । विपल्लिः पटुवीक्षिका ॥ मृगापुडैलीयिमिपापानृ ॥

श्रुयेवयमश्रुयां ॥ भूकाम्बेरा ॥ म्लानः शृम्मीरं पृशुश्वेकोटिः ॥

शृंलिकिश्रुक्रृष्णमंगुकंडशृङ्गृगुक्किकमं ॥ गडगादिद्वेबभिड ।

वेष्मसन्दानिकेडनम । निमातुपमृमगनठवनागागवभाकिवम ।

गदयभांभिक्षुमृत्रिकायुत्तिलयालयाः वासबुलीद्रुयेत्राला ।

महामंकृबवंड्रिंगं ॥ मडुप्रालंभगीगांडुपलकमालो एलोसि ।

याभ ॥ वैदमायशंडुन्हेवालिमाल्लाउभक्कदरा ॥ पुवमरंसि

न्दिमाल्लाकृ पापानीयपालिका ॥ म० मुकुहमिविल्लयं स ड

माला श्रुडिमुया ॥ वडुगांडुविदवभीगंफुडुमद्रिरात्य दम ॥

गठगार्वामगदंपवियुंपुडिकरादम ॥ कडिमशृगीविव

हृङः ॥ मदुमाल्लामिरिगादम । वाडायरंगवाकोषपृगीवेभ

उवारलः । केधुकमरुवाकमगुदयेभुलिनामूयः ॥ दमूलि ।

णनिवांवामुः ॥ पृमपद्विवक्कडुरुभ ॥ मोणेभुलिगलामउनभूय

कद्देपुकविक ॥ मभिकस्मवडेठेहृनेहूवगुमयेयिम ॥ विष्ठ

भृ॰ ङकपूर्ठिकदिठवंडीवरमस्मनाम ॥ भूगावंकुलुरभङ्गुय

कै॰ रभ्राडवरेणनम ॥ भुडुगुत्रावरेणत्रभूगाडुः कोमम्रुयाम ॥

पाषाणपुष्पमालिनी ब्रह्मदण्डी त्रिकण्टक गदेवगदलीप्रियङ्गु ॥
तृणमत्रगालिका ॥ पञ्चाङ्गुलिर्मिलिताग्निमाद्रुपर्णिका ॥
पुष्पकवल्लरी स्यादपमाक्षवंडुपत्रकम् ॥ वल्लीकरीपूपणलधात्री ॥
पणलङ्कटिः ॥ गोधावल्ली वल्लरीकण्टकारिका ॥ कर्पटपालि
कपालि विडङ्गं पञ्चमकम् ॥ श्रीब्रह्मद्रं पूतीदरः श्रावणिमुद्ब
ठिक ॥ उरल्लिश्रीवण्डिब्रह्म ग्रन्थरग्रन्थि श्रीगोधरम् ॥ क्षीरञ्चद्रुप्रियमूषित
पिष्टमिद्रुवरीय ॥ कवायमरदरुद्रविष्णुकृमिजलन्ता ॥ पुरोदा
शाद्रिपारं विद्युल्लिङ्गुपिरिजिनी मम्भस्तानी मणीशाक्रकरेणुक
मगधा ॥ क्षीरभारपरिष्करलम्बविषमतिकघ्नः ॥ मभीसंवमघ
गम्भीरवम्भकचामुरम्प्रियाम् ॥ गम्भारी उपमन्त्रश्रीमभीम ॥
प्रियामट ॥ पर्पटीरपत्रिश्रावकालम्भववालयः ॥ भयघ्नः ॥
मदीपमिषापविप्रमदद्रणमपवटः ॥ पद्मिनीङ्गिगिरिर्वारल
मल्लमिलिस्वया ॥ लेकालिकप्रवालः ॥ द्विक्षणमिकमभो ॥
पम्भुमनमः ॥ क्षीरमद्रुयप्रवपवटः ॥ जिमवाविपमिविसिभा
नृवाद्रवियाडुकः ॥ गतुभावनमृदम्बदनक्षएरुयैरागः ॥ जिभा
लयोद्रिगणमूलमलयद्रुमनामलः ॥ पावमम्भुमरप्र्यविपुलामम
नक्षिलामदमड ॥ क्षएश्रीमियपरम्बद्रपाडमुवएकेगः ॥ क्षएकै
श्रीविडमुदुः ॥ भूपुमकमरप्रियाम् ॥ उम्मपुभूवलमवारिमवादि

मुवलक्षणभूतशालिन्दशिडलमाविला गविकाक्षकमीमलेदगीमाम्भदिद्रुलाः
गजुकदेवमिरुद्वः पाडयमिरिमक्षवः ~

तिमिरारिः ॥ मरीचुकुम्भरावाश्रीदेवापाउविल्वेगुद ॥ गन्धुरंगाउमें
लाभुमृङः ॥ कुलेपलाणिरेः ॥ पाचिः सुयाभाकरभूद्रमयहद्दथ
वङः ॥ उपहककुद्दरामात्राकुमिकूत्रमणिहका ॥ णप्रमभेतचिल्लाहद्
नैरिकंङविमेषकः ॥ तिजक्रुक्रुष्णिवाक्कीवेल्लडामिघिपिदिडूडेर ॥
मैल्लवनः ॥ तिप्पणहरर्तविपिरंगादवंकारंवनभ ॥ भदरदृभ
रद्दभीगदराभानुविम्रुदः ॥ प्रामभूस्पवंज्ञाभिंवनभेवयड ॥
पभाहृगाल्किकणेदेपुवरेकुमवाल्कि ॥ पभागुरीदुउहूरंफ्ल
मदणरल्लंववभ ॥ भृाहैउदैवपभददवंभनुधैरेविडभ ॥ वीभृलि
गवलिपीक्ङिः मेल्लीलेपाभुगलाद्यः ॥ वहृववामग्रदेभृामद्रुरे
किरवेम्बिदि ॥ वकौमदीनदन्नापीविल्पीपाफपसुकः ॥ पत्रीकद
कुल्स्मलः पल्लामीरुद्रभागभो ॥ वारंमदहृदैलेपैधद्दैरपध
द्रुमंदरिः ॥ प्रधवि ठैलपाकग्रा ॥ भृादवनूठैलेगृदिः ॥ वहृैठलेव
केषीमठलवाढलिरठैलो ॥ मठलेठल्लगंठल्लहृकेमविकम
मदषः ठल्लत्रैरविकमिडभूरवनूमयभिप ॥ भूकरश्रीमवत्रङः ॥
हमुमापामिठःसृषः ॥ परेकेडपुष्कगन्देवल्लीङघडङिहड
लडभुडरिनीवीदकुल्मिकुलपमिहृपि ॥ नगाहूरेदकूक्षुय उद्येण
द्विकुक्षुयसूयः ॥ पश्रीरकुंफ्रः ॥ कुवस्मृकुलमापावणिभुरिः ॥ ममिमा
पालडेक्कत्रमापामालेमिठलाद ॥ मापामिठावेदः भूद्रुला

ग्रं गता लता ॥ शिरोऽग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः ॥ सारो मज्ज
रि त्वक् स्त्री वल्कं वल्कलमस्त्रियां ॥ काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् ॥
निष्कुहः कोटरं वा ना वल्लरी मञ्जरी स्त्रियौ ॥ पत्रं पलाशं छदनं दलं पर्णं छ
दः पुमान् ॥ पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ वृक्षा
दीनां फलं सस्यं वृन्तं प्रसवबन्धनम् ॥ आमे फले शलाटुः स्याच्छुष्के वानमु
भे त्रिषु ॥ क्षारको जालकं क्लीबे कलिका कोरकः पुमान् ॥ स्याद्गुच्छकस्तु स्तब
कः कुड्मलो मुकुलोऽस्त्रियाम् ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमं ॥
मकरन्दः पुष्परसः परागः सुमनोरजः ॥ द्विहीनं प्रसवे सर्वं हरीतक्या
दयः स्त्रियाम् ॥ आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले ॥ बार्हतं च फ
ले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फ
ले ॥ विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला ॥ बोधिद्रुमश्च
लदलः पिप्पलः कुञ्जराशनः ॥ अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिम
न्मथाः ॥ तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥ उदुम्बरो जन्तुफलो
यज्ञाङ्गो हेमदुग्धकः ॥ कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ सप्तप
र्णो विशालत्वक् शारदो विषमच्छदः ॥ आरग्वधे राजवृक्षशम्पाकचतुरङ्
गुलाः ॥ आरेवतव्याधिघातकृतमालसुवर्णकाः ॥
स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः ॥
पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ पारिभद्रे निम्बतरुर्मन्दा

पारिभद्रकः तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः वञ्जुलश्चित्रकृ
च्चाथ द्वौ पीतनकपीतनौ आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ वानप्र
स्थमधुष्ठीलौ जलजेऽत्र मधूलकः पीलौ गुडफलः स्रंसी तस्मिंस्तु
गिरिसम्भवे अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः पलाशे किंशु
कः पर्णो वातपोथोऽथ वेतसे रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः
द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे शोभाञ्जने शिग्रुतीक्ष्णगन्धक
क्षीवमोचकः रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ बिल्वे शाण्डि
ल्यशैलूषौ मालूरश्रीफलावपि, प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहु
पाद्वटः गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ आम्रश्चूतो रसा
लोऽसौ सहकारोऽतिसौरभः कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः राजादनं प्रियालः स्यात्स
न्नकद्रुर्धनुष्पटः गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका श्रीप
र्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः कर्कन्धूर्बदरी कोलिः कोलं
कुवलफेनिले सौवीरं बदरं कोलमथ स्वादुकण्टकः विकङ्क
तः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ऐरावतो नागरङ्गो नादेयीभू
मिजम्बुका तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके काके
न्दुः कुलकः काकतिन्दुकः काकपीलुके गोलीढो झाटलो घण्टापा
टलिर्मोक्षमुष्ककौ तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुकौ ।

पृ. क.

सीयलिकाञमानिकाञश्चीकिँडदकङ्लो ङमकपौडुला
ङ्हः सृदकुलीलाक्लाथभामनः ञमगुयपक्कुभकेशङ्हेश्रमक
कम ङ्लंमसीपश्रियककमश्राभुदलिश्रियँ वीरक्मेकक्ष
रेग्निभापीठल्लाउकीङ्घ गमठक्ककमरालकपीउरमथा
स्त्रकः श्लकस्रडिङिउीमिङ्गश्निकवॅपीडभालकँ मलकम
नवनुकपध्वश्रियकलीवकः मालेडुमलकवृाश्रकल्का
मनसृमंवरः नकीभलेवीरश्रविद्दृक्षञठेल्लनः गमम
नठलाहकेक्षीक्रियामघश्वयेः उक्तुमीडपमडनक्कल्ले
पन्निमडवक्मा पिङ्किलाप्रनीभीमाक्रियवश्वन्दलिङ्कु
यैः पिङ्कडुमलन्मलीवमुरेमनक्कुएमलन्दलिः मिंगविलै
नञभालःकरणश्रकरक्षकः पुकीदश्रीडिकरणःपुङी
कङ्कलिभारकः करक्षठेनःमञ्जुरेमकङणवल्लगी गेङि
रेङिडकश्रीदमङ्गङिभपध्वकः गायङ्गीवलडरयःपमि
रेङिडणवरः पविमेठेविक्षमिरेकमरक्लमिरेभिड मेमव
ल्केपृपहापृरष्कुगङ्गवदमक परङुञनङुकवङ्नमकङ्गि
ङकवंमः मङ्गपङ्गङ्गुलाभङ्गवठभारहरसुरः पलम
भीमभीरमृष्कुभीमङ्गुठलामिवा पिन्डीडकेमनपकःश्रवमन

करहाटकः शल्यश्च मदने शक्रपादपः पारिभद्रकः भद्रदारु
द्रुकिलिमं पीतदारु च दारु च पूतिकाष्ठं च सप्त स्युः देवदारुण्य द्व
योः पाटलिः पाटलामोघा काचस्थाली फलेरुहा कृष्ण
वृन्ता कुबेराक्षी स्वङ्गभृङ्गधूपालेला वमत्रुडत्रीअम्बीकीश्यामा
तु महिलाह्वया लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली वि
ष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा मण्डूकपर्णपत्रोर्णनट
कट्वङ्गटुण्टुकः स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटः शोण
कश्चारलोऽग्निमन्थलाह्वामलकी तिष्यफलामृता च वयःस्था त्रि
लिङ्गस्तु विभीतकः नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः
अभया त्वव्यथा पथ्या कायस्था पूतनामृता हरीतकी हैमवती चे
तकी श्रेयसी शिवा पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः
कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः पनसः कण्टकिफलो
निचुलो हिज्जलोऽम्बुजः काकोदुम्बरिका फल्गुः मलयूर्जघने
फला कम्मीविकरभालाग्रकपिलाभाफलेजुमा ब्जुआप
पिकाद्रुमाप्रियालिमुपमश्रिया अरिष्टः सर्वतोभद्रहिङ्गुनि
पृ. र्यासमालकः पिचुमर्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा क
के. पिला भस्मगर्भा सा शिरीषस्तु कपीतनः भण्डिलोऽप्यथ चाम्पेयः

पुलिङ्गेः क्षवकः तिलकः कल्कः सिन्धुवारं पर्णकाः नागकेसरः पुष्पदीप्यकः वकुले
नानाम्हूतिमाध्वमयैमयैविकमम्

35

स्यात्केदमथध्वजः … कलिका … केसरे
वकुलो वञ्जुलोऽशोके समौ करकदाडिमौ चाम्पेयः केसरो नागकेसरः
काञ्चनाह्वयः जया जयन्ती तर्कारी नादेयी वैजयन्तिका श्रीपर्णम
ग्निमन्थः स्यात्कणिका गणिकारिका जयोऽथ कुटजः शक्रो वत्सको गिरि
मल्लिका एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले कृष्णपाकफलावि
ग्नषेणाः करमर्दके कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि सि
न्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि वेणी खरा गरी देवताडो
जीमूत इत्यपि श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका भूपदी
शीतभीरुश्च सैवास्फोटा वनोद्भवा शेफालिका तु सुवहा निर्गुण्डी नीलि
का च सा सितासौ श्वेतसुरसा भूतवेशी अथ मागधी गणिका यूथिका
म्बष्ठा सा पीता हेमपुष्पिका अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी ल
ता सुमना मालती जातिः सप्तला नवमालिका माध्यं कुन्दं रक्तकस्तु
बन्धूको बन्धुजीवकः सहा कुमारी तरणिरम्लानस्तु महासहा ३३
तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः नीली झिण्टी द्वयोर्बाणा दासी चार्त
गलश्च सा सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे पीता कुर
ण्टको झिण्ट्यां तस्मिन्सहचरी द्वयोः ओड्रपुष्पं जपापुष्पं वज्रपु
ष्पं तिलस्य यत् प्रतिहासशतप्रासचण्डातहयमारकाः करवीरे

कगीरंउहकरगङ्किलाश्वको उमद्उक्किउवैप्उंणकुरककृपाहृयः
भाउलेभमगस्त्राभूकलेभाउलपइकः ठलप्ररीगीलप्ररीमको
भाउल्लुकः मभेरलेभमवकः ४मुपध्दैलिप्लकः लम्कीरेभृ
षपल्भमकण्ठिह्नरकुणेरको मिउलुकेश्पागीउमिइकेवक्रिमंऌ
कः पककवमकर्म्हेणलाल्कुपविकीभ्रः मरुवस्त्राकुपल्ल
उमुक्केलकभ्उापसो मिवमल्लीपामुपउ एकभुल्लेश्केवभः
वभ्वकमगीवमकदणीवत्रिकेहपि वम्रमगीकिवकदगुकु
मीउङ्किभउा लीवत्रिकमेभवल्लीविमल्लाभपुपल्लपि प्रवा
दुवीभपुरमभेरएउलगीभुवा भप्रलिकभपुम्लीगीकेल्ली
पील्लपल्लपि पाणभुक्षुविभुकल्लीभ्रापीमुयभीरमा एकभुी
लापापमेल्लीभ्रावीणवरउिक्रिक कण्डकुएभ्रगमेकरेडिल्ली
कदगेडिल्ली मभूपिउाकपुरुेमेवरुसीमउल्लामणी पुभ्रपुपा
लदहृभ्रकदुवाभ्रादभापल्ली भ्रेप्रेजमीकमिश्चिःकपिक
कुष्ठमकल्ली मिश्चिपविभुएगेणीदुवत्रीमाभ्रीकभ्रा भूहके्ल्ली
भउमूल्लीरभूग्रभकपल्लपि पपाभानस्त्रीपमेकेणभानव
मप्ररको शहजल्लीकेमवल्लीकिल्लिदीलरभस्त्री दक्रिका
पृ. भुकुल्लीपम्भहणीभुकुलापश्चिया पम्भवल्लीवालेयमाकवहर
कें.

वमक: ~ मक्षिसुविकमीलिक्षीममक्ष्कलमधिक मक्षुक
पक्षीठक्षीमीठक्षीयिएनवक्ष्पि यंमेयवामेदक्षमेणक्षया
मक्षामक: रैक्षीकक्षगक्षामनक्षगक्षगलक्ष पक्षिपक्षी
पवक्षक्षीमिरपक्षक्षिपक्षिक रैक्षविक्षामिंदखक्षीकलमि
वावनिक्षद विमक्षिकमक्षमीक्षपक्षीक्षदगीकक्षकशिक धूमेम
गीक्षलीक्षक्षदमक्षमामक्षिकेक्षपि ~ गीलीकलाक्षीयकिका
गृभीक्षमक्षपक्षिक वक्षीमीदक्षीउक्षमेक्षीक्षिलामगीलिगी
पवक्षक्षमेक्षमगाक्षीभवक्षिक्षमवक्षिक कलमेधीक्षक्षदला
वक्षमीक्षिक्षक्षपि गक्षपक्षलावैक्षदीममाणीमपलाकक्ष
उषक्षपिपक्षलीमोक्षीकेलाक्षकविपिपक्षी कपिवक्षीकेलव
क्षीमेयमीवमिर:धमाग मक्षंउमविककक्षमिक्षीगक्षीक्षक्ष
ला ~ पलक्षमाक्षिमगक्षक्षमंक्षक्षक्षकउक: गेकक्षकेगी
क्षकेवमक्षक्षक्षपि विक्षविवाक्षिविवागिविवेपविवमक
क्ष मक्षीभदेषंमावक्षीगवीदक्षिकमभे मक्षक्षलीवक्षक्ष
क्षीक्षक्षिक्षीवगीवगी क्षक्षक्षकीकपक्षीगपायक्षमउवगी ~
पुदेकरक्षपीक्षक्षकलीयकदगिक्षव: क्षवीपमक्षक्षादकद
विक्षपलगीक्षपि वमिक्षगक्षक्षक्षगेलेभीमउपविक क्षक्षा
देमवगीवैक्षमाक्षमिंक्षिक्षवामिका क्षमेक्षक्षवमिंदक्षवामिके

३८

वाणिमन्त्रिकः पुंस्त्रैणेगरिकलीमूर्द्विष्णुकन्नापराणिग्रा ५

कगद्गुकल्केक्केकिलाक्रेकवकराः मालेयकूष्मीडमिथ

कुम्भपरिकमिभी मिश्रीयाधूववीरुल्वेवल्लः भद्रीवगीगुन्दाम

मदनशूपवेल्लमभ्याभिक्कुला उकुलकाद्विमिखल्लविरूकः

ध्वंसंभकम् वलवद्दलकेथकुवारुमल्वध्विक मज्री

कणेश्रीदूकश्राद्दीमडरमेडिम मवाशकडिम्भवलाशिवणिरि

वत्सरिवर शिवाण्डीरमीशूभाधालिकीडुभवघेल्लिक कलाम

प्रवविदलाचमसूकलमोधिक मकुकंल्लीडकयश्रीमकुकंमश

यश्लिका विल्ववीकीरमल्लेमुगाप्पुर्डीडुयामिडा पराञ्चडविर

रीपूरकदर्म्बेडकगाञ्चिक लाक्कलीमारक्षीडेयधिपल्लीमकुला

मली पेरापश्मकम्बीदीर्घभपूर्वेलेमभमुकः गोपीशूभामारिवा

शूप्रमदेदलमारिका यष्टिमक्लिम्मिद्विलक्ष्मीप्वकुरूकयाः

मे कदलीवारणबूसारम्भममांसुफला कदलीलापकृपल्ली

डकाकमकुमदेहपि कङ्काकीडिफुलीसिंदोहपष्कीस्वक्कुण

द्रणी राजलीमरमारागभराक्रापराकलीडकलेभूक्कलाङ्कु

मीकङ्काकीमवदमभा विदारिगन्धांमुभजीमालपक्लीकिर्ता

मवा इष्किरीममञ्जुकदपीवाकिशीडिम करकलीडुभाप

पु. क. जम्भीडुवयङ्केदः गान्तकीनागवलाल्माहश्रावर्क

णभाजवेथेषकभूम्रुदण्लीमयीउकः एुङ्ग्रीयणैलिकएलो
नाद्दयीकुभिणभुक भृल्लाद्गलिकाग्रिमिापाककञ्लीठकाभिक
गेणायतिउभवदमभलीडलभलिक मणम्लीविमभीशृङ्ग
णिङ्कमविकभमे डमुलवल्लीडभुलीनाणवल्लुभृषङ्गिण दवे
णवेणककेडीकपिलाठम्रुणाङ्गिरी मलवाल्कमैलेयमणत्रि
दमिवाल्कं वाल्कमावथालङ्खमडमवुमडम्रुद वालंहायो
वङ्गिल्लुणिम्रुकेनभुनभम कलानुभादवडमुभ्रुभमीडलि
वाति मैलेयंडलपलीडुमैंदगणडुडणीभवा णङ्गिभिणठक्षुउ
भुवादमभमीरमा मदेरभ्रुडम्रुदकीङ्गलिनीभल्लकीडिम म
प्रिङ्गलाभुठिमेडणडकीणडभुभिका भड्लीकमम्रुलैंलानि
भुप्रिडम्लानथभा ग्रङ्गुयाडङ्गिकडमुकेकङ्गीरीःमडुरिः शा
णिभुक्लुवाविकशृंशृभुंयाकलममलं मङ्गिवीभिडभमीभृकेमी
भृषविडकः णणभलाभुडलीमिवाडभलकीडिम भुभु
रीकंपोभुरभवडवःडयेरकः डुभिङ्गमकडलकेलीमिवमा,
मवम्रुभी मभुणाद्दवीकेभम्रुभुणाभदभकः शृद्वषंशृभ
नायेकवलभम्रुकवकः भपिनाविदुमलडाकपेडमङ्गिवणीली
णभम्रुक्लकेभीमदम्रुदुयिल्लाभिरी मुङ्गिम्रुम्रुङ्गिवङ्कैलण
लंनायमभाठकी कम्रीभम्रुडवविकाभडलकमयाभूणे

ऊत्वत्ल्दमथंवांवथंधरिपेल्लवभ। अवगेश्वरगेनरुकैवडीभमु
कतिय गृह्णिपलंमुकंवढंथधंम्भोल्यरुक्कारे मकमलाद्गुयिसु
नाम्धक्कामेवीलडाल्लथ्थ: मभ्रद्धावत्रक्षिएवद्यल्लक्षियिकेहयि
उपश्रिरीलएमांभीलएल्लालिममाभिषी ड्रक्कडमकुंद्धकंह्रगं
मदंवरुककम। कद्गुरकेड्विडककलुकेवरुमाषक: मथहिए
डिभाहिस्तरएभमवभोवणम। माकाम्हंपडथ्वयकिडफुलीयेल्दमा
रिम: विमल्लाश्रिमिापारडाढलिनीमरखधुपि श्रामकानुा
स्तुगलाद्दृखेमीकस्रुरक: एन्हिह्रीडमहरीवपक्कुमिमवत्ररी
पइपलीद्वैमवडीथ्रलमीरीडिमावडी वयथक्वीडकंम्रलीभाथ
पल्लीमदमद डुग्रिकेनीरुढल्लाविश्विकपील्पल्लृयि ठडुरा
कवडीडङ्गीमरथध्वएगड्रिक पल्लाथलीडुमवदराम्रपुरुरमा
ममा माह्निरीमुहिकरुडामरुमृद्धुल्लेलिका मदमुवृठीमु
हिभ्रुवेडमञ्जरवेहयि रमस्कुरीमडकलीममद्धापदिटेहयि
लीवडीलीवरीलीवालीवरीयामथमूवा क्रुवमीहिमथकर:
मरुहथाम्हलीयक: किरडहिहितुनिश्रिनादहिहिस्रमयुल्ला
विमल्लाभाउल्लाढुविढेनामथकमेहयि वायमेल्लीश्राद्धरमा
कयभ्रावमरुल्लक: विरुन्दृमद्रिकपहक्कृड्डमुरपल्लृयि
पुरल्मिदरुहरगस्पुहमक्षयमातिक प्रल्येयेभुरकम्बीरपद्मप

ग्रल्पिपेकूरे भगवान्तिमवापद्मपाणीपद्मपाणि कण्दिन्तु
ककमञ्च दृरङ्गङ्गेरेमनीहपि थथग्रदम्भुगणेप्रकृधमञ्जक्रमकः
पद्मदङ्गवत्र्यकमञ्चपलाङ्गुमकमकः लग्भकमदृभोअदगिडेबम
देपणम(लमुरंगङ्ग्लानिधुमदकमभोकः भवत्रपावमेदघ्नी
विङ्गंमनिवड्लकम(श्राड्राडकम्ब्रीङलाधवणिङभ्भोडपल्हपि ॰
पापावङक्षिङ्कणीपरुणलिडिश्रङीलङ वाबिकंश्यमान्नश्राइय
ङीवल्लदृक्षिका विश्वङ्कनभियमाभ्रिवागदीवरमेंहपि माकवँदृश्र
गणेश्वङ्कककमारीडुवायमी मडधण्डानिडमङ्गङडिश्वङश्भमरामिनिः
धुवाङ्गधीकारवीमसमरग्रडुधूमारिली डशूंकमेङगणणेवला
ठङ्गवलीडिम णनीणेङ्ककाणेनगीणेडुनम्ब्रहवाङ्गी मंदमाबम
लीगङ्गुग्रलीमङ्गङ्गिकंहपि कहरीपिभलामेपिकारवेक्षङ्कणेङ्गकः
मधवीमाखङलकंपणेलखिङकपँडः ङमइकमङ्गककनरेवा
मककणेमियो ङङ्गाङकडुङश्रीशाडुभूलाब्रमडेभमे मिङगवा
भीगिडुभ्राविमालाङ्किमूबामली धमेधमुराभ्रकरेणगीरङ्गम
मश्रिला कलभूपमककघीङग्रलकंदिलमेमिक वाशुकंमाकठ
दम्भूःङवाङुमङपङ्गिक भदमधीरुठानहोमदगङ्गाबमामिडा
गेलेभीमडवीदमगादृभ्लीमङलमककः ङनविडेमेधमनामाग
मागमकमभ्रिपाम(भ्रादहभगकेगङ्गमलब्रक्रुणेम्बए ॥

वंमेङ्क्षरकमव ठासिभारघ्न न्सुणः मउयवायवछलेवे रुमङ्कर
डुल्नः कीमकवेभवमुधूः येश्वरक्रूविल्लेमुङः गृङ्किवायवपरुषी
गुदृमेलुत्नकङ्कुवः नरुमुणभायेष्णलेघेकमभाखुयाभ। उङ्कणनुः
येष्णलः थंङ्कभविडुवल्लुवः रभालङकुमुङ्किरुः थङ्कुकलुनकमयः
भृङ्खीवल्धीवरुवंभ्रलेमृभीवमखिुयाभ। घठयंनल्लठंसेहमभगुत्र
लंगलामयभ। लाभल्लकंलयलयमवढदेकुकयवे नल्लायमु
न्नाङ्कमूभाकंभुधायावधि पश्वीङमंङमेढङ्कयेविङ्मवकङल्न।
येरमोनिकष्टभल्नेवलणुकरोदिषभ। कङ्डुङ्कुयालखाभा
लाढल्नकङ्कुभुल्ले मध्वंवालढल्नंध्याभेयवमंढल्नभलनभ।
ढल्नांमेदविभुगुनङ्कुवरुमंदविः ढल्नवल्कयभालेनाविकं
लभुलाफली थेंगुशश्रगनुभकेगुवाकङ्कुथरेधुङ ढलमङ्किणमे
डेमदिवल्लमदिङ्गमृयः। पलुवङ्कडङ्कुङलीपलरीमङ्कल्नघूमः
वंवेषणिवनः ~ ~ ।सिंदेमगेढ्मयेङ्गमृद दमङ्कुमगेदविः॥
माङ्कलङ्गीपिनोङ्गाधुङवमगुमगोमढः॥ ववादमुकवेयङ्कगुंकं
लःपेवीकिविङ्किणिः। मंभूधिय्नीभुबुवेभाङ्कडेङ्कलवङइयि ऊ
ढलङ्कवंवमक्ष्यादिमंध्रुगुवियापलाङ्कलः॥ कयिङ्कवङ्कलवगमाया
मनवलीयायाः। मकंणवनवङ्कमीवंनीकायवलङ्कके अदमुङलु।
ढङ्कुकगाङ्कोयङ्कायङ्कोनो॥ ल्वलायेमदियेवाङ्कवङ्कमानेरिङ्कः॥

प्रियंमित्राङ्कुरिमायुगिमायुग...

४४

दक्कवेदस्नूक्क्लंकरुकवेभभो ॥ ववप्रियपैवक्कडक्किलःपिक ।
उदपि ॥ ककेकुकवणविभुवलिपभुमनम्रुणः पुष्कम्प्येपपवक ।
दुलिकुमायभापुपि ॥ दुलकककमुककेलेदुदक्कलकगुकः ॥
पुडपिमिल्लोदक्षपुण्ड्केकीवमुकेभभो ॥ [illegible] पवकक्कः ॥
पकुवफुमुभाभ्भः ॥ केकम्बवन्बकवाकेवपाङ्कयनाभकः ॥
कदम्बकुलदंभम्फूदड्डमकुकवेभभो ॥ दंभपुम्बडवाकडःमकुण ।
भावभोकभः ॥ वलदंभापुडेमकुमवलेवुदिडेचिदः ॥ भलिनेम
लिकाप्तायेणापुवपूप्चिडेउदेः ॥ मवसिवडिवणिप्रुमलाकाविभ
कम्प्रिक ॥ दंभमूर्येविद्रुवण्भोवभदंडुलम्म ॥ णडुकाणिनपङ्
प्राप्नवेल्लीडेलपापिक ॥ वठवभमिकवीलाभवप्याभप्रभमिक ॥
पडक्विकापडिकप्राफ्दंभभुवनभिक्षिक ॥ दंभीडम्नुडिवल्दप्राद्धेवे
लीपवणद्वयः ॥ दुक्ष्णीमीकवीवीकिल्लिकमन्नुयाभिभाः भभो ।
पडकुमलकापपदुडमाडिविक्कः ॥ णडिमलीकालिभेलिविक्रुनेप
कडदपि ॥ भपवडेभषकवेभषलिप्नपपालिनः ॥ विवन्दपव
लिकुमपदमकुभवालयः ॥ कमलम्नुक्षगीकम्बवेलम्कुद्धि
गेभभो ॥ भपुवेवदिल्वदीवीलकण्डुलणम्नुक ॥ मिपाव
लवीपीककीभेप्यनादवल्लामूपि ॥ केकवालीभपुवपुभभो ।
मम्कभमको ॥ मिपापुकमिपकभुपिम्कवडेवंभक ॥ पवे ।

कुमारकुमडादिगडवालिकुमिदमादिडभीविडंमुडंवा वदमरमपामूपकमाडंवपविलडीउभमाककविमुधं ~

बिदङ्ग, बिदा, बिदङ्गम, बिदयमः, मऊत्रिपक्षि, मऊनि, मऊउ,
मऊनङ्गिरः, [illegible]
किरः, [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

श्री १८५४६

धृ॰ीपमन्निरीवाभावति ड्रमदिलाड्घा ॥ विमेधाभुड्नाकीनः॥क
मिरीवामलमनु ॥ धूमदभावितीकाड्लन्नाराविडम्रिनी ॥ धम
वीरमन्नीराभांकृपतामेंवठमिनी ॥ वर्णदभडकमिहृडभावरवलि
री ॥ लडकिर्षकभदिषीठमिशुङ्गापरभिय ॥ भरीपालिन्नदोरीव
द्विडीयामदणडिली ॥ ठडएयाधपंकध्रिमवः॥ भूगुकुडहिली
धृष्णू ॥ द्वियमविहडभरीमाधीयद्विड ॥ लडभायद्विकद्वलविपिनाध
श्रयंवरा ॥ पांवरामवद ॥ मरुलभ्रूठूलपालिक ॥ कठाङभागीणो
गीडाद्विकानागडवा ॥ भूमहभादूधुरः॥ डदलीववङ्घिम ॥
ममः॥ भुवालीवधः॥ मिरठृीडमुवाभिनी ॥ डम्नावडीकणकन्ना
द्रुमघडीकणकी ॥ कङाठिनीडयायाडिमर्डं भाठिभारिका ॥
भुंन्नलीणदलीवडुङ्घ ॥ भडीभलठकुरी ॥ श्रीलीधांभलामभुद
द्विडीमिष्ठाविरा ॥ प्रवीनविष्नडिमर्डविम्नभुविडवभम ॥ पुलि
म्हायीवयडूमपद्वियरीअठकक ॥ ठड्पलिकीभ्रीडुरुड
मृडुणीभरी ॥ कुशीकुदङ्गदडूमुकुदडहडूविदूना ॥ पवीरीडम
दकठ्ठीयठि ॥ धयीमयस्मभा ॥ पडवीभ्रयमाड्डडकडियाकडिया
धूपि ॥ डपाणयाङ्गधाणायी ॥ धादठक्ष्मीनिभयः॥ प्रलाडुमीडयंयी
गस्नाइडीकडियीडघा ॥ डयाणयाङ्गुयाणयीपरधूपीभलमद्र ॥
वीरपडीवीरकदवीरभाडडुवीरधः ॥ णीवडकीणीवपलुडिएडु ॥

[illegible]

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः। पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मा-
तुलः। श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्या-
ज्जामाता दुहितुः पतिः। पितामहः पितृपिता तत्पिता प्रपितामहः। मातु-
र्मातामहाद्येवं सपिण्डास्तु सनाभयः। समानोदर्यसोदर्यसगर्भ्यसहज-
स्समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः। ज्ञातेयं बन्धुता ते-
षां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ। अमृ-
ते जारजः कुण्डो मृते भर्तरि गो-
लकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ। मातापितरौ पितरौ
मातरपितरौ पितरौ श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता
च। दम्पती जम्पती जायापती भार्यापती च तौ। गर्भाशयो जरायुः स्या-
दुल्बं च कललोऽस्त्रियाम्। सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ॥
तृतीयाप्रकृतिः षण्ढः क्लीबः पण्डो नपुंसके। शिशुत्वं शैशवं बाल्यं
तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्। पलितं
जरसा शौक्ल्यं केशादौ विस्रसा जरा। स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धया।
बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थवि-
रो वृद्धो जीनो जीर्णो जरन्नपि। वर्षीयान् दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्र-
जः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः। अमांसो दुर्बलश्छा-
तो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

[illegible]

पवलीपैयपाटल्लावहल्लुप्तामिकि, कैमवक्कीमिकक्कैमीवलिनैव
लिकम्भूभो, विकलाङ्गमुपेगाङ्ः, पवेकृयवल्लवामनः, पागञमूर्ध
गान्मौविमूविगडकामिकः, पिवन्मृदुवन्मः, धल्लुपूगडएकः॥
ऊवल्लऊवएवमूर्द्धम्लमंदडएङकः, भूतेडविरणिः, मङ्गलागुल्नः॥
ऊकवकूरमिः, कलमुकम्लुवाकालः, पलनडिमुट्टलपिकः, पमिवल
उमोमूलीः, पद्मिमदमुगमिडे, वुलिनक्केकवुपिडापलुमिमुएलवः॥
एतुलक्कलकः, पिभ्रमिलकमिलकालकः, पुगमयंमूपदुवहूं सि
किमरकृडिक्रिया, कैथरिमुण कैयहटगमैएयुविहपि, मीनगूए
मेपुऊपवैमहणिगरूभया, गमहूकफायमेपः, पुडिमायमुपीनमः॥
मीकऊ ऊकवः, गमिकमगुरूवयुः, गमाग, मठेमुमवयमम्रुपःपा
रूल्कएविपाटिक, किलामभिष्टुककुडुपामपामाविमलिकः
कडुछ लप्तक ऊया, विऊएः, पिएकंहिम, वुल्मियाभीमनःकौ
वेतापीवुल्नःगमाग, कैंठमफुलकऊमुः, मिविदवामकमभी, पवा
दमुचिरतमुकूदलीनकृवादिका, मक्कतिकवामिमवीरमांमु
वमपूवमाः, हाणिकेमा, विमपिमूलिऊगमदकगाडवाः, स्त्रीयरं
पाटवम्मीकं, समन्मयं हिमूल्नुकम, वम्नदीमहलक्कंमूउवेगु
तृवणमिम, वेगादतराक्कृवहिपवैहोमिकिक्क्रके, वणुतिवभयः
कलुउल्लायैविनडेगूदऊ, लागलागुपुमयावीविनडेहणिडभः

[illegible]

[illegible] [illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible] ॥ [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] मदन [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

पीलिः [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ पालि [illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible]

ग्रीवायां शिरोधिः कन्धरेत्यपि ॥ कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका ॥
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् । क्लीबे घ्राणं गन्धवहा घोणा
नासा च नासिका ॥ ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ॥ अधस्ताच्चिबुकं ॥
गण्डौ कपोलौ तत्परा हनुः ॥ रदना दशना दन्ता रदास्तालु तु काकुदम् । रस
ज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी ॥ ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां
भ्रुवौ स्त्रियाम् ॥ कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ लोचनं नयनं ने
त्रमीक्षणं चक्षुरक्षिणी ॥ दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ अ
पाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ॥ कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रव
णं श्रवः ॥ उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ॥ चिकुरः कुन्तलो वा
लः कचः केशः शिरोरुहः ॥ तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः ॥
ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ॥ कबरी केशवेशोऽथ धम्मि
ल्लः संयताः कचाः ॥ शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ वेणी प्रवे
णी शीर्षण्यशिरस्यौ विशदे कचे ॥ पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्
परे ॥ तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुंमुखे ॥ आकल्पवेषौ नेपथ्यं
प्रतिकर्म प्रसाधनम् ॥ दशैते त्रिष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः ॥
प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः ॥ विभ्राड्भ्राजिष्णुरोचिष्णू भूषा
तु स्यादलंक्रिया ॥ अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ मण्डनं चा
थ मुकुटं किरीटं पुंनपुंसकम् ॥ चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥

पु.
के.

वालपाश्या पारितथ्या पत्रपाश्या ललाटिका॥ कर्णिका तालपत्रं स्यात्कु
ण्डलं कर्णवेष्टनम्॥ ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका॥ स्व
र्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता॥ हारो मुक्तावली देवच्छन्दो
ऽसौ शतयष्टिकः॥ हारभेदा यष्टिभेदाद्गुच्छगुच्छार्द्धगोस्तनाः॥ अर्द्धहारो मा
णवक एकावल्येकयष्टिका॥ सैव नक्षत्रमाला स्यात्सप्तविंशतिमौ
क्तिकैः॥ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्॥ केयूरमङ्गदं
तुल्ये अङ्गुलीयकमूर्मिका॥ साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्॥
स्त्रीकट्यां मेखला काञ्ची सप्तकी रसना तथा॥ क्लीवे सारसनं चाथ पुंस्क
ट्यां शृङ्खलं त्रिषु॥ पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्॥
हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका॥ त्वक्फलकृमिरोमा
णि वस्त्रयोनिर्दश त्रिषु॥ वाल्कं क्षौमादि फालं तु कार्पासं वादरं च यत्॥ कौ
शेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्॥ अनाहतं निष्प्रवाणि तन्त्रकं
च नवाम्वरे॥ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्॥ पत्रोर्णं धौतकौ
शेयं वहुमूल्यं महाधनम्॥ क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥
स्त्रियां वहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः॥ दैर्घ्यमायाम आरोहः परि
णाहो विशालता॥ पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ॥ वस्त्रमा
च्छादनं वासः चैलं वसनमंशुकं॥ सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूल
शाटकः॥ निचोलः प्रच्छदपटः समौ रल्लककम्बलौ॥

समौह्लदशिकस्तुषा निचोलप्रच्छदपटः॥ समौ रल्लककम्बलौ॥ संव्या
नमुत्तरीयं च चोलः कूर्पासकः स्त्रियाः॥ नीशारः स्यात्प्रावरणे हिमानि
लनिवारणे॥ अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमस्त्रियाम्॥ स्यात्त्रिष्वाप्र
पदीनं तत्प्राप्नोत्याप्रपदं हि यत्॥ अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि॥
प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥ पेटस्मिक परिकरः पदक
स्नावमङ्गिक॥ वस्त्रलंकृतकजीवीवीमानमनंमृत्वयः॥ परिकर्माङ्ग
संस्कारः॥ मृष्टिर्मार्जना मृजा॥ उद्वर्तनोत्सादने द्वे समे॥ आप्लाव आप्ल
वः॥ स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्॥ पत्रलेखा पत्रा
ङ्गुलिरिमे स्त्रियाम्॥ तमालपत्रतिलकचित्रकाणि विशेषकं॥ द्विती
यं च तुरीयं च न स्त्रियामथ कुङ्कुमम्॥ काश्मीरजन्माग्निशिखं वरं बाह्ली
कपीतनं॥ रक्तसंकोचपिशुनं धीरं लोहितचन्दनं॥ लाक्षा राक्षा जतु क्ली
बे यावोऽलक्तो द्रुमामयः॥ लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्॥
कालीयकं च कालानुसार्यं चाथ समार्थकम्॥ वंशिकागुरुराजार्हलो
हकृमिजजोङ्गकम्॥ कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्॥
यक्षधूपः सर्जरसो रालसर्वरसावपि॥ बहुरूपोऽप्यथ वृकधूपकृत्रिमधू
पकौ॥ तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः॥ श्रीवासो वृक
पु. धूपोऽपि श्रीवेष्टसरलद्रवौ॥ मृगनाभिर्मृगमदः कस्तूरी चाथ कोल
के. कम्॥ कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम्॥ घनसारश्चन्द्रसंज्ञः॥

सितोऽहिमवाल्लकः ॥ गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ॥
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥ कालमेषी कृष्णफला वाकुची पूतिफल्यपि ॥
वरुणो मत्स्यगन्धा ॥ कणा ऊषणा मागधी पिप्पली ॥ कटुरोहिणी
कपुरीकक्कोलैलकाकमलः ॥ गाङ्गेरुकी पवीत्रिः वल्कलं श्रावणिके
पालम् ॥ त्रयन्तिका सर्षपा ॥ हविष्याम्बिडिश ॥ मण्डूकपर्णी भण्डीरी
नाड्यः पञ्चशब्दान्विता वनम् ॥ मालूरभल्लातकि ॥ विकङ्कत
शाकः ॥ पुत्रञ्जीवः शिलापत्री ॥ वृश्चिकाली लाङ्गलिका ॥ शूलपर्णी
कर्णस्फोटा ॥ कुङ्कुमं ॥ पिङ्गला ॥ यवितिक्ता मसूरविदला पाता
पीतद्रुमा ॥ मकरन्दः ॥ वृक्षरुहा ॥ तुणी पारिप्लवं ॥ कुमारी
पवना सूर्यावर्तयवनीयकं ॥ मधुकं ॥ भूम्यामलकी ॥ पञ्चाङ्गुलाम
मः ॥ तक्रककुद्मती ॥ बीजपूरः ॥ मातुलुङ्गः ॥ ओषधीः ॥ मधुपर्णकं
एकः ॥ पुत्रिका ॥ पीतद्रुः ॥ कुमारीकण्टकिका विषघ्नी लाङ्गलीका ॥
मन्दारमत्स्याक्षी हिलमोचिका शीतलकम् ॥ ~~ ओषधयः ~~
अथ तृणानि कुशं दर्भं पवित्रं ॥ वंशे त्वक्सारकर्मारत्वचिसार
तृणध्वजः ॥ विशङ्कुरिश्च वेणवः ॥ मस्करो मस्कर ॥ शतपर्वा
वीरणी ॥ वंशी ॥ तृणकुशं कुशमस्तकः ॥ मद्यं ॥ कशेरुकः ॥
मधुलवणं ॥ कुब्जकाशीतकोविदारः ॥ पुष्पैः ॥ शरः ॥
मुञ्जः ॥ तृणकं ॥ कुब्जवेतः ॥ विषघ्नं शष्पं ॥ सोमशकं मयूरा

[illegible]

[illegible]

ाडवाः ॥ विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्युतः ॥ विद्वान्विपश्चि
द्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डि
तः कविः । धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः । दूरदर्शी दी
र्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवा
दिनि ॥ वैशेषिके स्यादौलूक्यः [illegible] कापिलौ ॥ [illegible]
[illegible]वादिनि ॥ नैयायिकस्त्वाक्षपादः स्यात्स्याद्वादिक आर्हतः ॥
[illegible] चार्वाकलौ
कायतिका नास्तिको ॥ उपाध्यायोऽध्यापकोऽथ स निषेकादिकृद्गुरुः ॥ मन्त्र
व्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती । यष्टा च यजमानश्च स सोमवति
दीक्षितः ॥ इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ स गीष्पति
ष्ट्या स्थपतिः सोमपीथी तु सोमपाः ॥ सर्ववेदाः स येनेष्टो यागः सर्वस्व
दक्षिणः ॥ अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समा
वृत्तः ॥ सुत्वा त्वभिषवे कृते ॥ छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पि
काः ॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ सतीर्थ्यास्त्वेकगुरवः ॥
चितवानग्निमग्निचित् ॥ पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥
उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ॥ यज्ञः सवोऽध्वरो यागः सप्त
तन्तुर्मखः क्रतुः ॥ पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः । एते पञ्च
महायज्ञाः ब्रह्मयज्ञादिनामकाः ॥ समज्या परिषद्गोष्ठी सभासमिति,

[illegible]

[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
पृ. के. [illegible]

[illegible]

[illegible] ॥ [illegible] ॥

59

[illegible] ॥ [illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥ नियम [illegible]

[illegible] ॥ किन्तु [illegible] भिक्षुः [illegible]

कः पाशुपतिकः [illegible] कपाली [illegible] भिक्षु [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] कौल [illegible] ।

[illegible] ॥ [illegible] ॥

[illegible] ॥

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

सन्न्यासवत्यनशने पुमान्प्रायोऽथ वीरहा। नष्टाग्निः कुहना लोभान्मिथ्येर्या-
पथकल्पना॥ व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः। धर्मध्वजी
लिङ्गवृत्तिरवकीर्णी क्षतव्रतः॥ सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदे-
ति च। अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम्॥ परिवेत्तानुजोऽनूढे
ज्येष्ठे दारपरिग्रहात्। परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ। तथा प-
रिणयोद्वाहोपयामाः पाणिपीडनम्॥ व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं र-
तम्। त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥ सबलैस्तैश्चतुर्भद्रं
जन्यास्स्निग्धा वरस्य ये। ~ ~ ब्रह्मवर्गः ~ ~ मूर्धाभिषिक्तो रा-
जन्यो बाहुजः क्षत्रियो विराट्॥ राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षि-
तः॥ राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो नृ-
पोऽन्यो मण्डलेश्वरः॥ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञ-
या राज्ञः स सम्राडथ राजकम्। राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्॥
मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः। महामात्राः प्रधानानि पुरो-
धास्तु पुरोहितः॥ द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ। प्रतीहारो
द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः॥ रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ
समौ। स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु॥ भौरिकः कनकाध्यक्षो
रूप्याध्यक्षस्तु नैष्किकः। अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः॥ सौविद-
ल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते। षण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः॥

[illegible]
[illegible]

विनः ॥ विषयानुत्तरेनारश्मङ्गमिङ्गमङ्गपरमं ॥ उदभीनपरतस्वपीछ्लुंमा

जम्बुफ्लुडः ॥ विपोर्वविमपक्षाविद्धिवद्धुषण्डहृमः ॥ द्विहिपक्षदिडा

मिहूदमूमाडूवमडूवः ॥ वृक्षिपाडिपक्षादिशूहजिपविपक्षिनः ॥ वयमू

स्त्रिगुः सवयः पवमिङ्गभापामदडः ॥ माहमधुयमीनंष्टाहहृरेणूरवडु

नभः ॥ यवाद्धवल्लुपूरिणिरयमधद्रवद्धमः ॥ मारद्रुगुरुडपदयवुङः ॥

मूहयिङः सभौ ॥ संवद्धवलुडिविकिंदिवल्लुगाल्कवधि ॥ सुमेदगुडिकमौ

फ्रडुल्गुविकडाडिकावधि ॥ डुत्रुकिल्लुनमिङ्गः ॥ मङ्गीनदपडिस्मनौ लि

पिकर्पूरमल्लिकरमजुम्बुलपक ॥ लिपिडाफवविडामल्लिपिडिविद

ठल्मिपो ॥ मृगद्धवमदरेन्द्रडेहृदुखकमल्ली ॥ पश्चीवेपुरीपुष्टपैङ

पणिकडहपि ॥ भामाहमदक्कमराधूदनवल्लाविषू ॥ रहस्यविषून

डुपः पैनात्रमून्यपिपिम ॥ सविनाविगृदेयानभामंडठिमामयः ॥ वडु

प्रन्नक्रयमिपः ॥ स्तवेमूदमहुङः ॥ कयः त्रांमसच्छिद्रविवनीति

वक्तिनाम ॥ सभूयः स्तवमद्रयहेणक्किमदश्वमाम ॥ मामदरेठदमश्वुं

विक्रपायमडूधुयम ॥ माजमंडमढिरुः मामभामूमविममौ ठलैस

लपावूपणापमहेदयवीक ॥ पल्लविष्वमस्फीस्यमुडीयाकूगमर ॥

विविक्रविलानमक्रवविस्त्रलाकमुषावजः ॥ वदस्त्रपामुमलिमवदमू ॥

उरूवहिप ॥ सभौविमम्बविद्राभोहमेइमेयषिपिफ्रडे ॥ पहेमहाय ॥

कन्दमुडिमकुपंसमञ्जनम ॥ सक्तौपपिकंन्नहंठणमानाठिनीडवड ॥

[illegible]

न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम् । अववादस्तु निर्देशो निदेशः शासनं च स

ः शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ॥ आगोऽपराधो मन्तुश्च समे

तूद्दानबन्धने ॥ द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ॥ घट्टादिदेयं शुल्कोऽस्त्री ॥

प्राभृतं तु प्रदेशनम् । उपायनमुपग्राह्यमुपहारस्तथोपदा । यौतकादि

तु यद्देयं सुदायो हरणं च तत् । तत्कालस्तु तदात्वं स्यादुत्तरः काल

आयतिः सांदृष्टिकं फलं सद्य उदर्कः फलमुत्त

रम् । अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं

स्वपक्षप्रभवं भयम् । प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् । नृपा

सनं यत्तद्भद्रासनं सिंहासनं तु तत् । हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् ॥

भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका । निवेशः शिबिरं षण्ढे सज्जनं

तूपरक्षणम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् । दन्ती दन्तावलो

हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नागः कुञ्जरो वारणः करी इभ ।

स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशा

वकः । प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ । हास्तिकं गजता वृन्दे करि

णी धेनुका वशा । गण्डः कटो मदो दानं वमथुः करशीकरः । कुम्भौ तु पिण्डौ शि

रसस्तयोर्मध्ये विदुः पुमान् । अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् ।

अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका । अधःकुम्भस्य वाहित्थं प्रतिमान ।

पृ. के. मधोऽस्य यत् । आसनं स्कन्धदेशः स्यात् पद्मकं बिन्दुजालकम् । पक्षभागः पार्श्वभागो ॥

रुतुठगामुयँगुडः ॥ स्त्रिप्रवपस्तुल्लाञ्छदिकमोगाञ्चवरेहभाग ॥ उँद्वँवँग

कभालारंवञ्जुभुम्रेघम्नट्वाले ॥ पद्मकेविगङ्गेश्रीपाद्रकुमेभुीमटलिः ॥ पि

यं ॥ प्रध्याकश्रावराश्यामूकुल्टनामल्लानामम ॥ प्रवेदम्पुरमावलः ॥ पर्मि

मधुष्ठेवृयैः ॥ वीडंकुआरंदमूलकं वामीडुगणएवञ्जुी ॥ ध्यत्कैवीडिडुरग ॥

उरुम्बवुरकृमः ॥ वालिवादवगाउवदयभैवुवमभुयः ॥ पुरुणीय ॥

कुलीनाकूः ॥ विवीडम्नप्रवाजिनः ॥ बनायुएयाविमककुभुएवाड्वि ॥

कदयाः ॥ यथरस्त्रिवमणीयूएयनभुएवाणिकः ॥ फ्लुमेकुीमिडक

कैरघ्रूवैरुतरघमृयः ॥ गालक्षिमेरैवामूस्तावदवाभाडवंगाल ॥ शिखरी

नंयदभ्रूवरलिनैकुनगश्टडु ॥ कमूंडुमपभस्रावांदिवाहिधामनिम्रुः ॥

विगालभुगलिर्ध्रुमकढ्ढडस्त्रीयभुरुवड ॥ पदाम्पक्षयल्कंवल्ला ॥

गन्धिकधामभाः ॥ प्रभुद्विडंनेरिडुकं ॥ रमिडवाल्लिसंभ्रुडं ॥ गडयभ्रेपं

कुणनाथ्पैश्रुडुशेषमभिुयभा ॥ कविकडुपल्लीरभीमढल्लीवेशर ॥

पैभाग ॥ भक्कुीलिमलाकुलेवालदमुस्रवालणिः ॥ शिग्रुपावडुल

क्रिडेपरावढुभरुडुवि ॥ यावंमक्लिपिपधुजमडफमृदरेवः ॥

मृभेपवुरमघ्नहूयानेरूभमरयपग ॥ कल्रीरमवैवदलंदयमं ॥

मभंधयम ॥ क्लीवेनरुकुटैभ्रीश्राम्रहीकम्भलिवाहकम ॥ मिविका

पाधूयानंश्राढ्ढलापुष्पद्धिकामिुयाम ॥ उकैडुद्रुमवैयाभूश्लीपि

मिद्रकडरव ॥ पाण्डुकषलमवीडः शृतपाण्डुकमली ॥ रघकपल ॥

णेरिडंवल्लिडंणवः प्रुडमुडुलिडंहूमाउ ॥ डडुलिडंमतिभिक्षुमिमापुनगेणीः ॥ णेरिडंगतिभाद्वयहिणं

वल्लिडंमः प्रजकयममल्लामाकुल्लिडशुंगडहिकम ॥ प्रवामगेमगडःहूमाणगेमल्प्रुडमे ॥ उडुलिडं

मह्यवेनयेलंगभ्रघपत्रया ॥ डडुलिडंडुवगाकूम्रगलिमापमृडि ॥

[illegible]

घपराड्डुपथर्क्कशालमृगाहृप्स्वृ मायकः पञ्चाङ्गुलो ... ।
शुण्डरः । शृङ्कट्वाङ्गुकट्टीरः मार्जीकः ... कः । याष्टीक ।
पारम्रण्किका ... कि । ... मिकोमि ... ।
कर्कोटिको । मधीफलकपालिः ... कः । ... ।
... ।
... ।
... ।
... ।
... ।
यात्रिकः ... ।
... ।
संस्पर्शा ... ।
... ।
... ।
... ।
... ।
... ।
... ।

... ।
... ।
...

न्वशरासनकोदण्डकार्मुकम् । इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥
कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ । कोटिरस्याटनी गोधे तले ज्या-
घातवारणे । लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । स्यात्प्रत्या-
लीढमालीढमित्यादि स्थानपञ्चकम् । लक्षं लक्ष्यं शरव्यं च शराभ्यास उ-
पासनम् । पृषत्कबाणविशिखा अजिह्मगखगाशुगाः । कलम्ब-
मार्गणशराः पत्री रोप इषुर्द्वयोः । प्रक्ष्वेडनास्तु नाराचाः पक्षो वाज-
स्त्रिषूत्तरे । निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥ तूणोपासङ्ग-
तूणीरनिषङ्गा इषुधिर्द्वयोः । तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।
कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् । त्सरुः खड्गादिमुष्टौ स्या-
न्मेखला तन्निबन्धनम् । फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः । द्रुघ-
णो मुद्गरघनौ स्यादीली करवालिका । भिन्दिपालः सृगस्तुल्यौ परिघः प-
रिघातिनः । द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः । स्याच्छस्त्री चासि-
पुत्री च छुरिका चासिधेनुका । वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रि-
याम् । प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः । सर्वाभिसारः स-
र्वौघः सर्वसंनहनार्थकः । लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥
यत्सेनयाभिगमनमरौ तदभिषेणनम् । यात्रा व्रज्याभिनिर्याणं प्रस्था-
प्र. नं गमनं गमः । स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् । अहितान्प्रत्य-
कै. भीतस्य रणे यानमभिक्रमः । वैतालिका बोधकराः चाक्रिका घाण्टिकाः ।

प्रवृः पौराणिकः स्वर्गभागगणार्थं मम भक्तः वर्द्धितं मिद्भल्लवस्तु स्मृत्वा मद्भमे क्रियः

ऽकाः सुदुर्गगणानुभगणा वद्धिरस्तुतिर्याऽङ्कः संमंथकमुमभये
मल्लूभाद्विवद्धिरः रोगद्भूयैः श्रियां तुलिः यांभुशां रद्भ्येरणः प्र
ह्लेक्षेदभूमयदिलू पिल्लूलोरुमभाङ्गले यजाकवैणपद्गीशुङ्गेतं
युणमश्रियाम् आवीरमममं ग्रहकुमिदरिठयश्रद मदंप्रवम
डंप्रचमिहदंप्रविकश्रियाम् पदेश्मक्षिकरुद्यदृष्टाद्भुवरा
ह्मति यदमदमिकउमा शद्दमदंउयेठवहृद्ध्वरः शुवियंडर
भदेवन्न सोदालिश्रुमयुधंदर मक्रियैरक्हमधूलिविद्रूमश्नुतिम
क्रिउ वीरपानंद्वयद्धनंकडकविश्रियाम युद्भुभायेणंणटंभूणंख
विरुवलम मठभास्कदनंमहृं समीकंमाम्यवायिकम वश्रियां
ममवरीकरमद्भ्रकुलदविगूढे सभूदवाठिमम्यउकलिमंडेए
संयुगाः पृष्ठमदममायाउमल्लूभाहृगभाङ्गवः ममटयःश्रियां
संयद्भमिहलिममिहृवः वियंडुंवादयहुन्नुउमलंवूलमकुलेश्रीग
दुसिंदवाद्भुधाकरिश्रुयोयाए क्रूदंयेणसंरवेद्धंजिकोगा
लिउमः विमदरेणवमशूरः पएदपृवेरमभो भूमठंडवलाक्षरे
दंघमलिर्डकलमम वणटंक्षीवतुद्धउउपमनेस्मसंरयमम्रुण्ड
उकमम्लंमदेभूवमठमुपीडभ पृहवमुक्तंवृहमाद्रवंविए
घेणयः वैरमुद्धिःश्रुगीकवैवैरविद्भुवंमाभौ पूदूवेद्भूवसंपूवःप
दृयेविमूवेदूवः यपदूमेयवानं मद्लिकमः पराणयः परावितय

रक्तदेहित्वात्मुक्तिविदितो ॥ प्रभावकं विकलं विकरणं विमायलम् ।

ध्रुवाश्रमं पराश्रमं विश्रमणं विजितश्रमम् । विवासनं संस्थापनं विनष्टन

भयाश्रमम् । विष्टयलं विदावनं कालं पविचलनम् । विवायलं वि

समस्तं भावरूलं मुक्तिप्रदायकम् । उत्तमं भूमधं तत्त्वं तेज्ञमनविस पु

लकं पिञ्जविमलप्रपाउंक्रमकुरवणनृपि ॥ श्रीपाद्गं विमलं कमलंसवि

भजनम् ॥ सुप्रदष्टुकलणाद्विविघ्नान्तुं शीलयन्ति यः ॥ पठेत्रिसन्ध्यं यो

नरः सत्यं विणं विशिष्टयं ॥ प्रभावं पुलिनं कृतिदोकिंमासंयुक्तिमिलनं ॥

परमश्रद्धया पदकुर्वन्ति पुण्यं सम्भवः ॥ सत्यश्रीतो ह्रिंद्धिं सिद्धिमिह ॥

सिद्धिः स्मृयः कर्वन्तुं श्रीप्रियायाप्रुक्त्मपप्रहकलेवरम् ॥ सम्मानं श्रुष्टि

द्रवं क्रुल्पपश्रवभस्मियां ॥ भगदेवगदेवमूर्तिकगं श्रद्धनुवाल्य ॥

धर्मिक्कभूमवुः सुग्रः सर्वं लीवं भुणवल्भा ॥ गुणलीविदकलेना ॥

लीवाद्लीविजयते ~ ~ कृदयवनः ~ ~ उक्तश्रुक्तपरम

दाहं स्माक्रुभिम्भ सेविमः ॥ प्रुलीवं लीविकवाशाद्धिलीवनयतेन ॥

स्मिपांरुषिपीमुपालुं वालिलुंप्रतिदुयः ॥ सेवासुद्धितुमकंदृषि ॥

दक्षुमिलं क्रुतम् ॥ श्रियामिदुयामिदुयैः यथाभक्तिं सत्यसदे ॥ महद

तंवालिंहृवः सुग्रदलं पदमक्तनम् ॥ उक्तुरिंत्रभयेण सुक्रभीदंकृष्टि

लीविक ॥ यामलयां युयामिदकं ॥ वियमाक्षपमिदकम् ॥ उतमत्रुणमह्रि

देभयेकृगाद्कोरमाउ ॥ क्रुभीमिकेवाद्यकेदमुलीवमुवावयिः ॥

कल्पवरक्रुतद्धुः मा
ध्रुवप्रतव्यः सदेकेश्रम
स्माउ ~ मसीमदिनउउ
पक्कुराणारमविजयपक्षु
क्रुवमिवरुदप्रदुगमह

कवेरमपास्यर्दं
क्रुतवमः स्थयवं ॥

कल्पः यमादिक्रुत
कल्पक्रुतदिम
कल्पक्रुदयरूण
कल्पदिकमदिक्रुत

पु
क

70

तिलपिञ्जश्च निष्फले॥ क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी॥ स्त्रियौ
कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा॥ मातुलानी तु भङ्गायां व्रीहिभेद
स्त्वणुः पुमान्॥ किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी॥ धान्यं व्रीहि
स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥ नाडी नालं च काण्डोस्य पलालोस्त्री
स निष्फलः॥ कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्॥ शूकोस्त्री
श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे॥ ऋद्धमावसितं धान्यं पूतं तु बहुली
कृतम्॥ माषादयः शमीधान्ये शूकधान्ये यवादयः॥ शालयः कलमा
द्याश्च षष्टिकाद्याश्च पुंस्यमी॥ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका॥
अयोग्रं मुसलोस्त्री स्यादुदूखलमुलूखलम्॥ प्रस्फोटनं शूर्पमस्त्री
चालनी तितउः पुमान्॥ स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥
समानौ रसवत्यां तु पाकस्थानमहानसे॥ पौरोगवस्तदध्यक्षः सूपका
रास्तु वल्लवाः॥ आरालिका आन्धसिकाः सूदा औदनिका गुणाः॥ आपूपि
कः कान्दविको भक्षकार इमे त्रिषु॥ अश्मन्तमुद्धानमधिश्रयणी चुल्लि
रन्तिका॥ अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि॥ हसन्यप्यथ न स्त्री
स्यादङ्गारोलातमुल्मुकम्॥ क्लीबेम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रि
याम्॥ अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका॥ पिठरः स्थाल्यु
खा कुण्डं कलशस्तु त्रिषु द्वयोः॥ घटः कुटनिपावस्त्री शरावो वर्धमा
प॰ के॰ नकः॥ ऋजीषं पिष्टपचनं कंसोस्त्री पानभाजनम्॥ कुतूः कृत्तेः स्नेहपात्रं।

शैवालन्द्रन्तुश्च शैभाग ॥ अवभावृषपं ठष्टं धाञ्च भृङ्गमठण्णभं ॥
मविक्कश्विक्कलकमशृदुद्ध्रमदनमुकः ॥ वशीमाकं दाविडकं मिशू ॥
स्पृक्काशालिका कटम्बपुष्कलशुक्लवेयवाचउपश्चकरः ॥ उत्तिडीकम
मर्कं मलकाक्षशुणवेल्लरणभ ॥ भतिमं केलकेशकृष्टशुवलं ताम्रपउ
नं ॥ नीलके नीलवल्ली एनीकवल्लनष्टउलीरकं ॥ पयवीकम्बीप
श्रीपश्चक्कलेपुरुष्कक ॥ पश्चकं मन्दवीरं शृदवक्कड ॥ विश्वकर्ण ॥
उमुभुचमपणशाकमपवमशुरीभदिवणभ ॥ भीरभमकर्पविश्वद्वा
गरविश्वठवणभ ॥ उवन्नलकमम्बीरउन्नमपादिवृडविड ॥ पच
त्रिभिभणशापुङ्गत्लानिडकक्लिकभं ॥ मदचवपिलतुकं कल्लीकं ॥
दिष्कराभ०भं ॥ पगुरुनगनुमृदुगूड्डआमनभिरचि ॥ डमही कपवी ॥
पश्चीवाषिककवपीपवः ॥ विमाष्ठकठ्ठीपीडदविद्रुपचवल्लि
पी ॥ भाभदूपयुलवलभपद्मीववृभिरंमडड ॥ शैनुवर्षुशीमीडमिच ॥
मल्लिवतुंसमितुलं ॥ रैभकंवमुकंपाकंविडमदुडकंदुचं ॥
भोचवल्लमृगमकेडिलकं डरमपक ॥ मदृदीठल्लिडं पादवि
कोगमकुवाभिडा ॥ ठलिकशीर विलडिशृदूमालाडुभालिरा ॥
शृंडभरडुविधूर्णं डिलिद्दवामिडववणः ॥ ममृडं भधिमाडूशा
भाधिद्भुटणिकं मुभाड ॥ टकलावल्लिकं डमूदूधिमुलवण्ण
॥ भूआ ॥ मृङ्गलालडठठिनिडं मम्भदृभाशुडंडुपैभिभ ॥ म्लीडमपुम

मद्वत्रभृषमं स्त्रम्भं मन्दुरम ॥ स्पृग्धिस्किलं विलिलं संपदुं मोठि

उमभ ॥ सिकं ॥ मस्त ॥ श्रियुरन्तं कविडवासिड ॥ सुपक्तां पोलि

रहुपेलाप ॥ यंकुभ्रिमुमाड: ॥ पश्वक स्पृशित्रिपाएकेणनाद्यसुयव ।

सियः प्रपंप्रपः पिशुकम्पृकं रणि मभुवः ॥ सिम्बश्रीठउम

[illegible] ॥ सिम्दएदगिुक ॥ मवरमा गुमहुम

सियाभ ॥ भामगा मामविस्म वामकृहउममनहुवे ॥ यवापु कुष्ठि

कमा ॥ विलीं पीडरला मभा ॥ भमा स्तुदस्ता उल्लेलसमगाड़ि

लेदनः ॥ गातृशिपगवं मवं गोविदूमयमसियाभ ॥ उदुपुक्तक

गीषिश्रीः दगुंमीवंयषस्यमभ ॥ पयस्मा [illegible] दिस्मंसदणिप

रेउवमु ॥ [illegible] विसमधिन्नकवींडं वेकृउम ॥ उदुदपदवी

नंयदृगोमे दद्वंयस्तउम ॥ [illegible] कलमीयमरिभुमपितोव

मः [illegible] पादम्भु चाभुनिलनभ ॥ मद्दणि दवं

मभुपीपुषठिनवंपयः [illegible] कृमभुकवल्ना

कः ॥ मपीरिस्कुर्ती उन्तूयाम मशिः ॥ श्रीमदठेल्लन ॥ उदसदुपिपा

माडद दपंलिगुवृ ठेल्लनभ ॥ एभमं लोकं मृदरोविधमे राम

उदपि ॥ मोदिदंडदलं ॥ दशिः फेलाकृतिमभल्लिउम ॥ कमं स्क

मंपूदृत्रुक मपुयवोधिद ॥ गोपगोपालगोमस्थ गोगाहीर ॥

वल्लवाः ॥ गोमहिष्यादिकं पादवद्धं ॥ गोगवेष्टं ॥ गोमान्गोमी ॥

[illegible]

[illegible]

लंतुगीणवंश्याक्षवांशलः ॥ द्विधावित्रक्षवीतंश्रज्ञवेयग्रामिडशेग ॥ ३

क्षठहूवल्लीवद्धठपठिक्लपठिक्लपः ॥ पगत्रुमेगठयिगीज्ञद्धुक्षंमंदरि ॥

गीक्षकभ ॥ गहृगीहगवांवक्ष ॥ णवेवाक्षकुठेंश्रकभ ॥ क्लपिमपक्षदि

कश्यारुक्षिमसुलगक्लपः ॥ उयत्रउकतरुकेक ॥ अहृएरभुडलकः ॥

मलक्षतिभुवक्षत्र्यारुक्षश्चवमडरेभभो ॥ प्रष्टहस्क्लपल्ह उपष्टः ॥ मध्गी

पतिविक्षुः ॥ क्षक्षदिमथुक्षवादः ॥ भ्याडगलकमलः ॥ प्याव्रमिडभु ॥

नभृङ्गः ॥ पश्वाहृगापाद्युगः ॥ युगलीगांगवद्धरेवुगुशभक्षताक

ए ॥ पवत्रिरिश्रक्षितश्भुंदालिकभैतिको ॥ प्रवद्गुद्गोरेयप्रषीत्र ॥

भ्रप्ररक्षुगः ॥ उकवेकुपशीलेंकपृवाव्रेकपृवावदि ॥ मडभवपशीलेयि ॥

ठम्रसुदपश्चवदः ॥ भादेयीभीगठेंयीगीहुशभाक्ष ॥ मसुक्षिली ॥ प

नद्दुदीपु ॥ बगठि ॥ सक्षल्लाहुदीडवा ॥ पलुद्भूयेदिलीष्ट्याडुभा ॥

गीभुरेंमिकी ॥ बरुक्षिकडेमत्क्षुः ॥ मवल्लीएवल्लादयः ॥ क्षिदय

गीक्षिवद्यगी ॥ रेकद्धड्ड कंदयी ॥ मडवक्षमडुदयरुवंहुक्ष ॥ दियगी

वमायक्षवंक्तकुपवक्षक्षपभत्रिगी ॥ पुरुजुकपठेश्ठुत्रवेदगी

ठैपयाविषी ॥ कल्लीपुमदपुलनेयद्धीपीदालगठिल्ली ॥ शृह्मक्षगी ॥

दुभकरारुक्षप्रतिपेयंमुक ॥ मिवपुक्षक्षयिल्लीगवक्ष्क्षवप्रति

का ॥ पवक्षरभापसक्षहापीरेपीपीयरभुगी ॥ मुल्लगीमुद्दिल्लदया

णेवमात्रकुक्षिडा ॥ मभंमभीगाभायेवशतिवंद्धः ॥ श्रपयङ ॥ ऊणभु ॥

[illegible]

१० [illegible]

८ [illegible]

[illegible]

[illegible]

उद्गले॥ तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुला॥ आचितो दश
भाराः स्युः शाकटो भार आचितः॥ कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिके
पणः॥ अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥ कुडवः प्रस्थ इत्या-
द्याः परिमाणार्थकाः पृथक्॥ पादस्तुरीयो भागः स्यादंशभागौ तु वण्ट-
कः॥ द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु॥ हिरण्यं द्रविणं द्युम्नम
र्थरैविभवा अपि॥ स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते॥ ताभ्यां यद
न्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्॥ गारुत्मतं मरकतमश्मगर्भो हरि-
न्मणिः॥ शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्॥ मुक्ताथ विद्रुमः पुंसि
प्रवालः पुंनपुंसकम्॥ [illegible]॥ रत्नं
मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥ स्वर्णं सुवर्णं कनकं हिरण्यं हेम
हाटकम्॥ तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्॥ चामीकरं जा-
तरूपं महारजतकाञ्चने॥ रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्॥
[illegible]॥ अलङ्कारसुवर्णं यच्छृङ्गी
कनकमित्यदः॥ दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥ रीतिः स्त्रि-
यामारकूटो न स्त्रियां [illegible]॥ [illegible]
[illegible]
[illegible]
[illegible]

76

मञ्जुरं सिंजनसिङ्किमूले ॥ अवंशः तृष्णासंलिदं विकूपस्तुयसकूमी ॥
मवलं रत्नाइं उपभृंगीत्रिर्कं शृंइ धारख, मीसंसमीमरं मैवमधूलिदा
रिमकाड ॥ कारङ्कैमिखरपलौरमधूइड्रपारडे ॥ गवलंभार्किषंमञ्ज ॥
पङ्कं गिरिश्मलो ॥ मेङ्ग्रंइ मोवीरं कापेड्ग्र पाभरभ। इइङ्ग
नं मिसिपर्णीवंषिड्वकमयुसकम ॥ कपरीङ्गविकङ्गा घेङ्कवंइङ्गरम
ङ्ग्रभ ॥ रमणठं उङ्कमैलंगाङ्गम्भविइगाविकः ॥ मोगाविकङ्गपङ्क
भूङ्ग लालूडङ्ग लङ्गिका ॥ मीडिवर्ध्वं पुष्पकंइ, पोष्मिकं ङ्ग भमाङ्गरन ॥
पिङ्गांपीइरं ङ्गलं भालेसदरिङ्गलकं ॥ गैरयमङ्गंगिरिसलामङ्ग
णंइ मिलाणइ ॥ वेलगङ्गरम, धूलपिङ्गगीपरमाम्भभाः ॥ क्रिङ्गीरङ्ग
कङ्गःङ्गैः ॥ मिड्रंरगामङ्कवं ॥ मङ्गरङ्गपल्गाङ्गरपकङ्गीनपिषु
कम ॥ रागभीमकृषेगेमधू वशूल्शिशुपिङ्गरसे, रङ्गषङ्गेपङ्गवपिसधू
लेषकमल्लेइरम ॥ शङ्गमपेवाक्रिमिपंमदरीणनसिइपि ॥ मेवक
भूलङ्गलपः ॥ ममैलंममलमवि ॥ मपङ्गेइभाङ्गिकम्मि ॥ मपङ्गिघूं
इमिङ्गकम ॥ मासिलाभङ्गेधूभम्फ्रनागलिङ्गिक, नेपाली,
ऊषणाेगेला ॥ यवफरेयवाणूलः ॥ पङ्कैषभूलिकामाराः कपेड,
स्थापवनकः ॥ मोवङ्गलं शूदूमकं ॥ रङ्गीगंमरंधा ॥ मिणधूस्त्र
इमगिसंमैसरटेप्रलमैमवम ॥ ग्रन्थिकं पिप्पलीमूलं चटिकाशिर
इत्यपि ॥ गोलोमी शङ्कइकेमेषापइङ्गं रङ्गमपरम ॥ ङ्गिकपङ्गपल्शृषंङ्गि

[illegible]

[illegible]

[illegible]

लाङ्गलादिकम् ॥ ~ शूद्रवर्गः ~ ॥ शूद्राश्चावरवर्णा
श्च वृषलाश्च जघन्यजाः ॥ आचण्डालात्तु संकीर्णा अम्बष्ठकरणादयः ॥
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनः ॥ शूद्राक्षत्रिययोरुग्रो माग
धः क्षत्रियाविशोः ॥ माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः ॥ ब्राह्मण्यां
क्षत्रियात्सूतस्तस्यां वैदेहको विशः ॥ रथकारस्तु माहिष्यात्करण्यां य
स्य सम्भवः ॥ स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ कारुः शिल्पी ॥
संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ॥ कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु
मालिकः ॥ कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः ॥ तन्तुवायः कुवि
न्दः स्यात्तुन्नवायस्तु सौचिकः ॥ रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः ॥
पादूकृच्चर्मकारः स्याद्व्योकारो लोहकारकः ॥ नाडिन्धमः स्वर्णकारः कला
दो रुक्मकारकः ॥ स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः ॥ तक्षा तु
वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् ॥ ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधी
नकः ॥ क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः ॥ निर्णेजकः स्या
द्रजकः शौण्डिको मण्डहारकः ॥ जाबालः स्यादजाजीवो देवाजीवी
स्तु देवलः ॥ स्यान्माया शाम्बरी [illegible] ॥
[illegible] ॥ शैलालिनस्तु शैलूषा जाया
जीवाः कृशाश्विनः ॥ भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ मार्दङ्गि
का मौरजिकाः पाणिवादास्तु पाणिघाः ॥ वेणुध्माः स्युर्वैणविका वीणा

वाद्यास्तु वैणिकः ॥ जीवान्तकः शाकुनिके द्वौ वागुरिकजालिकौ ॥ वैतंसि
कः कौटिकश्च मांसिकश्च समं त्रयम् ॥ भृतके भृतिभुक्कर्मकरो वैतनिको
ऽपि सः ॥ वार्त्तावहो वैवधिको भारवाहस्तु भारिकः ॥ विवर्णः पामरो नीचः
प्राकृतश्च पृथग्जनः ॥ निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ भृत्ये
दासेरदासेयदासगोप्यकचेटकाः ॥ नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचार
काः ॥ पराचितपरिस्कन्दपरजातपरैधिताः ॥ मन्दस्तुन्दपरिमृज आलस्यः
शीतकोऽलसोऽनुष्णः ॥ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ॥ चण्डाल
प्लवमातङ्गदिवाकीर्त्तिजनङ्गमाः ॥ निषादश्वपचावन्तेवासिचाण्डालपुक्क
साः ॥ भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ व्याधो मृगवधाजीवो मृग
युर्लुब्धकोऽपि सः ॥ कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ शुनको भ
षकश्वा स्यादलर्कस्तु स योगितः ॥ श्वा विश्वकद्रुर्मृगयाकुशलः सरमा
शुनी ॥ विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः ॥ आच्छोदनं मृगव्यं स्या
दाखेटो मृगया स्त्रियां ॥ दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः ॥
चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ प्रतिरोधिपरास्कन्दिपाटच्चर
मलिम्लुचाः ॥ चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने ॥ वीतंस
स्तूपकरणं बन्धने मृगपक्षिणाम् ॥ उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥
शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ॥ उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ पुंसि वेमा वाय

रुद्रः शुक्लाशिवातिउत्तवः शाल्मलिः शिशुपांत्रुत्रुपंत्रुलेधूमिकमालि ॥
पाञ्चालिका पुटिका मूत्रमुद्गामलिकिसूरा शाङ्गलठलिका पुष्पेले ॥
श्रीवाल्लिकवितका गन्धपुष्पिका रडलत्तुपंत्रुपुष्पश्रिख पिच्छकः पिच्छकः ॥
पिशाचपालावित्तमलिका तुरयपश्रुमलम्भः मिश्रकर्मवपावका ॥
पाञ्चरूपा नन्दीसेवावपतीनायमायिडा नक्षीवशीवराशशाद्मस्वादु ॥
मागधीकथा मञ्जलिका उकण्ठेलवल्लीश्रमज्वलवल्लकी नागपीशा ॥
दीर्घशिका मानभुविकचक्रूपः पुन्नागपैरपरसुवीविककलिकासम ॥
तैलमायपुरीश्रमाधूपुमसप्रसविका पुण्डरीकीवर्णविकाजपालीक ॥
पुरीसम कमारप्रविजकतीलकोपाधालमराः रुकमीसीकरपई ॥
शूर्पशूपमदनमलिक प्रमीपुलस्तिजपुटिमा शिलरकलानिकिंकम ॥
पुटिमानंपुटिविषं पुटिमापुडियारसा पुटिमुद्गायापुडिवविरुना ३ नमिपुडि
विति मृपुमिपुमानंपुतर ~ वासुलिनसुम्भमपुलुसामद्दमअसहमत
दक भातरलसमुपातमुत्रसुहूपसदरुभी निहभङ्गसरीकमपुडी
कर्मपुमामपः कदमपुपुविणमहदूपपैनमवेदनमा दरदंकरलं
शुरुपुनिवेमपेलडपूपि मगजविशियादलापविमूलवमहर
गमुडुभामूमत्रैरुकनमुद्दपैविमूडा दशंवस्त्रादरमाकल्पेण्डक
पिमायनम महिरुकर्मपहमपुवर्ण्णमसुठमलभ सुकपामभ
नमृपंमपद्यानमदृक्यमा मद्यासर्विमाणवकैमप्रभाम्रीकमहृषिः

सुपमपलिपदमप्रविडमपिविमध दैलिपुमपविसनादिडः श्रीषः मलूप्लैगकमपमपुपविकायामावत्तिमङ्गि

स्वस्ति इतिसिद्धः ~

मैरेयमासवः शीधुर्मेदको जगलः समौ । संधानं स्यादभिषवः किण्वं पुंसि
तु नग्नहूः । कारोत्तमः सुरामण्ड आपानं पानगोष्ठिका । चषकोऽस्त्री पानपात्रं
सरकोऽप्यनुतर्षणम् । धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः । स्युर्लग्नकाः
प्रतिभुवः सभिकाः द्यूतकारकाः । द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ।
पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते । परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम्
अष्टापदं शारिफलं । प्राणिद्यूतं समाह्वयः ~ उक्ता भूरि
प्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः । ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ~ ~
शूद्रवर्गः ~ ~ श्रीमदमरसिंहकृतौ नामलिङ्गानुशासने भूम्यादिक
काण्डो द्वितीयः ~ ~ ~ ॥ २ ॥

१०
कं

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

कः [illegible] ॥ [illegible]

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] ॥

83

नीलिपङ्कपिष्टकं वत्सदराढिवाढके मागन्धङ्कडकोदिमूष्टाद्रविष्णुमुव

रः उच्चाङ्कलुत्तुटाङ्गवाङ्गिलुवङ्गास्फमो विराकरिष्णुः मिश्रस्तूम

दृष्टिप्रमुभेदरः स्तुडुडुविदरविघ्नः विकमीतुविकस्वरः विश्वङ्कुर

विश्वभरः प्रमारीमविमाविलि सजिष्णुसदनः क्रजाङिङ्गिङ्गः म

मिजाक्षमी हूणर्निमध्यलक्रुपीयरङ्गमूहड्डकपितः एगाझकेलगाविडाख्य

लिङ्गधूमलातिङः श्वश्रूक्कायालविदूलः विदूलमयिडेममौ धरम्भ

पिपीतमीरः सूमृदवातपूर्णभापः दिवारगुडुदिभिवकृद्विवकृद्विवगाङ

डि यस्मदगुडुडिमहूकसपिंदृष्टिरिफुडि वत्सवदिवर्गबिबझवागीम

वाझाडिस्मक्ष्मो वासियसिपदवाम्नीवाबडकम्बवझाडि भाल्लाल्यकम्

वामालवामाएरकगाढ्वाक ममापिमापदारबहुगपोमलक्ष्मः श्रियं

वम लिदलम्हुकूड्येवोमन्हवामीतुकदूटः समोक्रवामझमरोक्षा

दमोश्रुश्रुवश्रुवः यवलम्बुवकृतगामीवामीरामीकरस्मभौ लक्ष्मीतुर

लगूकमुवक्रुंमूतुममिझिडि डकीमीलमुक्रश्रीकेरपूवामाझिग

भूरः विष्णुमिडवकमुस्तूदपम्बगुलुष्णिक्षुडः प्रडगवडिक्रडम्भू

दूपिडस्मगुडिस्मगमो पूहदिमुरिरमुमूमूहाश्रुडिविमाजडः विद

डम्भूद्विबूलडविधूलबूमुवक्षिडः मादड धूडिदडः धूडिवद्वेद

डस्त्रमः पणिजिपुः पूगिमिपुरम्भूकीलिडमंयडो पुपवप्रपम्भूडम्भू

क्रुडिमीकिठयम्भूडः प्रडक्रिडः क्रविडेडिमम्भूमंकम्भकेम्भि हप

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

म्लउ्या्ज्यृमुार्वकृथः प्रियमञ्चिनः वैतालिकविरवाङस्मि

उमुमतिम्निः रेणुर्द्वयोःस्त्रियांधूलिःपांसुर्नागदगः उभिभुयेन

येत्रिमुक्षपयमूलिकेणनः गदेमुवेगदेनमीपिश्वमुवेषमंम्

उः मुदनपूरुउः मूल्लवेथाप्रुरुपनीममा नीलीमाणम्भिरुवमेदेद

रिट्टिगगउयुरः प्रमीनउपविमुमुडन्नुमृत्रुभुम्मत्रिमउयदपूउ

मुापगउहः पमंदुव्रूमुणभाप कपिषुकेमिषुमुषुवविषुअविषु

वंदिधुः किथक्षामूहीहिउपकपीवरनमूकम्नभः माणिमुमृ

पिष्ठुष्टेप्नुणाविषुम्नमिथुवमिषुः वाणम्नायउरदल्लेगुदवामुन

वमनवकाउमये गाभ्नृगमीयकगमीम्नवभ्भिवेवलेमुउ गेदिउं

मषिउंमृषुंमृउशणं विषमेवुउम उपाषिउंमलिउकंमृमुउमृदिउमु

ठमा प्रमिउनिमिउंप्रलिप्रविउंठविउं माउमा मउफ्भिउं मृगेषुं शाम

उनउंविउङकमा हजिउमाणः मिषुंमिषुमृश्चममूम्निउमा मद्मु

म्निउं मउउंउुगीयंउदमाम्भिउ मृम्नुउम्निधुमन्वमृम्निउक्ष विउम्बधि

उे मृत्रम्नीमेत्रिउवीउंधूकमृधूकणेन्दुए ॥ विमवर्गलिङ्गवनः ॥

भूनउिरहयाह्दूंमक्षीलेलिम्नमुवयेउ कमदहियाउझडइगाम्

मृभुपवम्दनः माकल्नामृत्रवमनेपायायल्उुगायल्न यदुमुत्रे

विउपदिउमुत्रहसृत्राविलकल्लमा ममथभुममज्ञातिः मत्रिमुम

मधुद्रमः ॥ प्रपन्नकंकमन्दकं ॥ कमनन्तं भूणावल्लभ ॥ वमक्रियासंस्कारं ॥

प्रलकमन्दकमल्लभ ॥ विप्रसेविप्रवरंडमल्लभूरील्लभास्वरभ ॥ यद

भ्रिमृदद्विदल्लंजगुणवल्लभिदपि ॥ सेवरंसीवरंग्रुडिः ॥ विषयभ्र

एतंतिमं ॥ प्रहेमनाभमडीयह्नः ॥ संवेदवेद्यानना ॥ संग्रहनमतिष्ठा

भियास्तुठिमंजनाभूता ॥ वरांकुरोत्खड्गवायकनभठल्लवे ॥ प्रथम्ह

नमधरसायः ॥ संश्रयः ॥ कपिलया ॥ गदेन्द्रेवमल्ककीरवल्कुभूल्लय

भृद्गल ॥ श्रेणवेणप्रमापाकेदवेन्द्रदवेवचकु ॥ छप्रलीखेनयनायह

निलीलेकुमेकुमो ॥ मठडिवल्लुपबाहाडपख्यक्रिपठेभूवमत्व ॥ पण

अमल्लोपमृवनप्रमृवल्लपूभिडेरूमा ॥ यग्रडिप्रमवस्रडेरभूपारव्रह्म

पृथक्रम ॥ उञ्चडिडिमयेमतिः ॥ ब्रेषविषयप्रमृये ॥ क्रियायांकृपल्लगीलिः ॥

गिरेगुरवल्लभुक्रमे ॥ उवायउवयेमायः ॥ मूपल्लयपवेल्लयः ॥ विगलेरि

गाढमादेभमडद्रवाडक्रमे ॥ विमलंपविमलेकूपपडिवगूढः ॥ विग्

दम्नुविरेणमूलठियेगमूठिगूढः ॥ मधुरगादमनुभक्रोदेडिम्रेदमर ॥

विम्रवो ॥ वनूरंभूमिडिमूवः ॥ मदनमद्मुपडभवि ॥ विकरेविभकरमू ॥

दकरमुतुनडक्मिडभ ॥ भूविरमेविकरेद्रुममेविज्ञडिविहिये ॥ प्रपद

रमूपमय ॥ अमादरमदमूवयः ॥ भूढदवउपारंविदवमुपविद्रुमः ॥

प्. क. मठिदवेठिगूढल्लविदवेडूवकद्धां ॥ प्रदवेभकरमूढढभापाम ॥

स्यः॥ श्वादस्तुपृच्छाद्युस्नृन्मूर्वां दिगामनंवदिः॥ वियाभवियमेयामेय॥
मसंदर्यमसंयमो॥ दिंमाकमदिमारस्नृस्नादहणगाद्ध्वयः॥ विश्वेद्राय॥
मृदुदः श्राद्धपश्चात्तिकमूय॥ नित्रैमउपठिगस्नृद्धनिमधपैगिक्रिया॥
विषरंदुखविल्लेधठिस्नृयस्थरू॥ पुमयः॥ मक्रीपवनमममत्रपदवस्नृ॥
निरेणनमं॥ पनिमद्यपरीभारः॥ श्राद्वश्राद्धमनाक्तिद्विः॥ विमुगविपु॥
देस्त्राभः॥ ममनमद्रावविमुरः॥ श्राप्रदमंभवद्गविनामस्नुदमवं॥
मनुवस्नृद्द॥ विमयाद्रुमरमुविमधलं॥ गीर्वकमुवयामस्नृस्मविति॥
स्वक्तिकघलमे॥ लवठिलावलयननिम्रवपैवरपव॥ स्नुगवस्नृ॥
द्रुवमरमूमरस्नुरवसुनम॥ पुलणरस्नृदपमरः॥ स्नमरपुलयममी॥
णेमक्ति॥ विश्वभमेस्नृदुमसूभ॥ दनमस्त्रवः॥ पुदुस्नुभपैयगाजः॥ स्नुद्गमस्नृ॥
द्रुपद्रुमः॥ श्रामदादनमद्रुदृव्रमस्यस्नृमस्नुर॥ पडिवद्रुपैडिस्नुम्मि॥
ववायमुनिपात्र॥ उपलस्नृस्नुवठवः॥ ममालस्नृविलिपदं॥ विमलस्नि॥
विपुर्यंगोविलस्नृस्नृद्भिमलनं॥ विमूधवमुघृडिस्प्रडिरवमाघृडिएणारः॥
निपाणनियंकेपं॥ दुमसुभी॥ मनदम॥ प्रदीनस्त्रसूवीक्तमेमूलकेस्म॥
द्रमद्रमी॥ प्रद्रीक्तलं॥ विमयनंभानलंस्नुगास्त्रमृगः॥ पनिरस्यपैरि॥
स्नुदः॥ अंलेखउपगुदाम॥ सिवरूदुनिहूनं॥ द्रुवगालिकनस्नि॥
पुहाप्राणं॥ निरमंवपृदस्मेनिरपडिः॥ दुपमार्यविमापस्नृपदायम

चक्राङ्गी ॥ चक्रांगं मण्डीयाम ह्रूलीयामधमज्ञकके ॥ शृङ्गाटकमेविष
दमीहृदयपुष्पविपदये ॥ पदये त्रिकूलमभिदनत्रिपाउ उपाहयः ॥
धूम्रलयक्षमाक्षयउइशृङ्गाट्टि माभगमा ॥ मंगावमुक्रउध्यामुद्रि
क्षमिद्विणामदनामा ॥ विणघउक्रूडयस्कपुकधूमउक्रा: मुण्डस
मुमुण्डमनः मुण्डियेनविदम्हउ ॥ पुष्पितेविष्टउयेसउइविश्रुक्रमति
भः उक्करसुविकरसुर्व्वणहेक्पत्रज्ञको ॥ विगारेक्रूपविक्रवे ॥
क्रूदमुपदेज्ञकिपु । पुगरुवरत्रिविरउयउपगमेषामिंयांपुति
पूवः विपुत्रिविपुविरं विपुवरमिह फिंजाजगि ॥ पुवगणउत्रिमद्रिमुपु
मानेक्ष्टमकपुरवणउत्रि: उमपणमुपमुपेरागमक्रुवलिविहमयसुपाय ॥
गेशश्रेहमुमूवमभिद्दप्पुगविकम्विंपुप्रपिकंमापुलिकमेवभा
हमऋउमं ॥ मालयागांपुमालपूंमदयागांमदयउ ॥ दलूंदलानां ॥
पाक्रष्टपाबहेंतुद्विणामदनामा ॥ डॅवपमुकांपष्पुमंपामुपषूमगरू
माउ ॥ पलागांपलिशीपलाधूममागमूकंटलभमा ॥ गामङुणगउा ॥
पुष्पपम्हाजन्तापेंपकमका ॥ सपिमादमकुगेपवाम्दग्रम्वेवस्र ॥
मिकमा ॥ पयकणेनुलेक्रूदः पुष्पिपउिषुगलूरउा ॥ मक्रांगक्रुंगुमलम
पृ. मकेरमगागगा ॥ पलिपाउमुमुनयः पुलयमक्षुगागगा ॥ मवपुपेविउा
के. पमाक्रउर्पिवक्रुपिउमा ॥ मीविरिमेमिचिदः पिदसाधूवमगउा ॥

पुष्करवसन्तवंगवोविनयाकूउभामयः पद्मपालीपरिष्वङ्गप्रभा

रमुमहत्कुलभ विगर्तवमनीयडमुड्दनमुडिहमः दीरेहग

मुलाकक्षाक्रियामिभुवि कल्दाम विडकमुकपाल मुंकोभीह

मुलिगीपत्रा ॥ मक्षीलवनः १ ॥ नानाजक्केपिकनुमि

वनेमुवाइकीडिडः क्षरिभूयैगायेयेभुपदयेष्वपिडेभुडु कडः ।

पुकमेडिरिविरकोलेकमुडुवरेणर पद्दुयमनिमल्लेकुःमराप

कुमभायकः एभुकोकुिभुवनल्पुप्रकोविरयोककु पुले

कोडमतेद्दिडिडेठरीपदकभारकेः उमनमिकयेरकः कलके

कूपवामयेः उमकेनागवठरीरकक्ष्म्ह एकिप्रदयेः भाकडवेद

मिभुम्रंयंमिकक्षमिरेभुमेः श्राद्दलकेमुक्कणटेमक्षयपठकमि

क्षक उन्तकेकिरिलप्यूक्ष मल्लिपाभुमयपमकः कपहलीमक

रकः भगाडेमविनायकः किम्भुदमुविडभुमक्षुककीएमदक्षि

कः भूडिक्षाल्लेभुडीकमिपुभुक्रुमेमम्रयंभूयम श्राक्षडीकंडुक्षुवि

मुकद्वलेकक्षमल्पिम लेभिकयांमयेम्रमकोमाडकपुकद्व

ले मिडुमापकिरेमेमवल्कुंमूहादपमिडके डिलकल्कुमपि

पुनकेवाद्रीकंरमठपिम भरमगुमुनल्लकटालणाडेप ।

कोमिकः मक्षपमकनाडकः भल्देपिक्लुनूकमिपुप एपामक ।

पञ्चऌं भङ्गीकं भूक्नङ्गीकाकाखवि
भङ्गीकमिठकङ्गभङ्गीकवृविवृनः।

स्नुमाङ्केपि। पविधृ, स्वमृवडकः॥ हाष्टूपि, वि धंङगीकेनाय॥ वाहामपि, सीय
कः॥ भालाङ्कक, ङ्कपि, केधु, स्वाम स्नुल्लेपि, गीविकम॥ थीगुङ्गपिहंली
कंभूलमलीकं उधिपेटडे, मीलावयावद्रकेड्रु मल्केमकलवङ्कल॥
भाधुमडभवल्पांदभू रेङ्कथल्पलै, दीमायेपिमग्धिपूगीकल्कैसी
भमलेंतुमे: मफ्लुषपिनाकेभीङ्कलमङ्करणवृवे:॥ णेवकयुकरि
ङ्गुंपमूमेपफलेमकलिका॥ करिकायाडनाबहे: कलिकिकल
ङ्गथल्लि, करिवभुाङ्कलीपद्मवीणकेमुंडिभुव, वद्मस्कोङ्गपिम
ष्टावङ्केभाष्टाहकेवला॥ भूमद्मिकङ्कोउलिकेयम्लाङ्गवीवउम्रल:॥
ललाटिकं भूढेंठलमनीकदक्रमस्वय:॥ भाकेपञ्जिमिस्रमष्टव
डेडविनायक: भदकभूमविकवेभूङ्कयभपिल्वुक: येएकेथि
धृकङेपिगुवे, मेभूम, मेमिकं:॥ पिएकोगु भडलको॥ णीवगपिस
एलिकं:॥ भध्मवेल्लेमकिफ्लल्क: मुङ्केभुी ठवपिम॥ भूङ्कल्लेलघृ
कुलिकावाभुकंठवकमयें:॥ करिहंभ्मापिगाल्किकं रुगकोवल॥
ठेमको॥ भवेधृवेलभ्रकभ्रूहङ्के, मवम्नमगल्भृ: भङ्कम्नभ्रुिं
कभङ्क्रोपएङ्केवभमचके ॥ पाङ्ग: भव्रापम्भिङ्कवम्रुलाभुलि॥
गाल्लेमिलीधापी॥ मङ्किविलेललाएभ्रिकभ्रेनभीङ्गियपिपभं॥
भ्रलिफुलेङ्कपिमिापडभलेपपिगेभापभं॥ ॥ गाभ्र: स्रुषगा

पृ॰
कं॰

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

गाङ्गेरुकपल्लाविन्दिरे एभ ग्रङ्कोकिशिवभक्तिरे ॥ उक्का कन्दपिपापरु भूमिमाप

कृवन्ध वृषयेः ~ वृक्षाः ~ द्रुमपृष्ठतुयेतराठं पुगार्ठं ग्रमतरुकुयः ॥

मसृमुलाशिवदकेश्रुतेविटपुमंदज्ञो ~ प्रशुाः ~ वल्ली ठकेमु

ल्गाठेवालोवलिमठोमर ॥ कोल्लिरिभ्रक्षणठ्वं मेमंध्यारेश्वमघगुल्मः ॥

पल्लीकुरुपसिस्रुस्रवृष्ठठे प्रसूनविपिम ॥ भोठठंपुष्ठप्रासिरेभहकोसेदम

कूलिकेगुल्मः ॥ विद्दापपक्षिरे कालविमेघक्षवयेःसालः ॥ वक्तशिर

लामुक्तामेमुरेपल्लुवाफ्टर ॥ गूमालीनुपिरे ध्वमिवृक्षगुमाणिपारि

ष ॥ ऊल्ममघामिल्लेभिग्रामवरेमातुराकुवेः ॥ दत्तिल्लीष्मार्कलीदमपशि

माद्रविज्ञाया ॥ द्विषपाक्षेमदशिलः ॥ भुल्लभुग्नमवेमतः ॥ ममुमठ्दा

धिपामेद्वुलाशुभाकदलयपुल ॥ वल्लिकुघपिविपलिःनगघरट्टकापा

कल्मी ॥ कवेर्गुहामुर्निकठ्छविलेतुवल्लठनभ ॥ मवल्लभद्रविलाईः ॥

मीपल्लकमललेपिम ॥ विषाक्षिभावलिदवणाउकंलीवापरेशिव ॥

पुमालंदेरुभर्हुग्नमामुयुदुापुमारुप ॥ करल्लमाणकरभक्ता इशाशमु

यस्वपि ॥ पुरुषामेभमरल्लभुमभ्राठरप्रगाडो ॥ प्मुरुपघवधवाउघेप

भर्गुरल्लभूवय ॥ परशिघुविघाल्लृष्पदमुमदक्तकुन्दयेः ॥ मघल्लहम

विधिर्हांप्रकान्नपुरयध्मघ ॥ मकोलकेलिविषिदुामकुावराल्मकुरम्पुषाने ॥

मिठेरवकनल्वेवल्लीरमीवाप्दकामसुय ~ उनुः ~ प्लवमदावि

वमेत्रोमरघमुनावकलुवो ॥ पक्षिउकृगकमत्रोमणेठपपकिल्ले ॥

पयःपूरोऽतुमके ज्ञाली ग्रन्थिमपवृत्ते॥ दन्तीत्वपाशिनगहं भद्रोपवत्रा
भवेत् यशद्भिपके प्ररोहण्डतिपिधूति॥ यामपाद्रमिमोपडेः प्रडेः पृ
छत्रामातडे॥ गृदकोदभूलके डुः पाञ्जिवडनयमतः॥ मूपाडिः कनक ठगंपि॥
कुशकुथिगरन्धपं॥ प्रगाठिपक्ष्टपापिदुः श्रीज्ञवमाषिमा॥ विश्वाव
धूलिग्डूराक्षोप्रडमधुधूरिभागवो॥ हुतः पर्ष्ठपिलधुराणुठमानुरिमव
॥ भाडशुकुरवोधकुजाइयायां मकुडुले॥ कगातुमहद्रुकवाल्युक
रकिकुमवापुयः॥ पुगडुप्नमभदगुम्राजीवद्रुमेषयः॥ जगातुयभमिमु
गुम्वाज्ञमलकद्रुम॥ त्रिभ्रमिरामिनगजकिः भदकुडवाविडहुरुः॥
उम्नियाभूमाविजडिम्नुषयोनिम्रुणउवः॥ कमूरुरापिसृकुपउपमूर
भवगोमर॥ कम्रमामकृपयेमुजिः प्रडिकुणिहूकयर्यः॥ पडिः पीतुगव
मूर्हिहडिम्नमाष्टलमदः॥ विमुरवल्कुत्रुडिवमडीर्गाषुवभूयः॥
मृपारवयरेपमितिस्मदरिमरादभानयः॥ भूरागभूरुयगीरिगीडिकि कि
म्बूरवामयः॥ उम्मयोणिगामेपांघ्रः द्भृडाग्रिडियपुरा॥ वीरूठमूपि॥
भदडीकुडिकमदतिभमदमि॥ नरीरगादेशुमानांठगवटवभक्टर॥ म
मनिठायांभमिडिः मृयवाभामापिमिडिः॥ रवगुमिम्रमभुमवकि
फुलाभूदेडयः॥ एणगडीलगाडिमुकुविमपापिक्रिडायपि॥ पक्रिमु
रुपिमुमभमृपाडुरुयपिमायडिः॥ पडिनडेमरुलेतुपमाडिपिकठ
पृ.
के. हयेः॥ भृगरिदेनिलिङ्गमरुकैमिकूप्राष्ठवडयः॥ मिकडाभ्रुचालकपि

[illegible]

गमयँभुीजम्बिण्णुलालेगुरो ॥ ममजखिपुमजिम्ब अमम्बुजादि
उशिषु ॥ दमभीमुीमीाााागाग्नुवेषीपदृष्टपि ॥ शभुरीयशुयेरु ॥
भुम्भुीभानुभानयः ॥ मानुमूषि॥यंगेनुः ॥ मंभ्राणर्षिडुभृडुे ॥ दगः ॥
पकिशयवमोम्बद्रवंद्वेलीभुउवउरो ॥ पपवाटेउविरल्लुदयमि
भउवनुवो ॥ पाटरम्भुडिदुदंमाः ममृदुकुगुभरदः ॥ निवाद्विलनवा
दपिमादिल्लभुलमध्वयः ॥ मावबुमडिउद्गुदन्द्वेदकलबल्ल ॥
मृाद्रुसादुरोरणपिग्रद ॥ मृाहूद्धनधिम गभुएक्षपिगविद्रुदध्धृ
भेदवङ्दः ॥ भृणष्टेगलालिङ्गमरबाङ्ककजयेभुयं ॥ भुीमंविहुनम
मृधाक्रियाकुगालिनामभ ॥ णदेगदमृपुनिषहृदृउेवद्भ्रनमठउ ॥ धमं
हृवभिठिहा॥भुवलम्बुङ्ग्रिवभुष ॥ गेष्ठकंमविडेभारभुठिभुाजहमा
भदरम ॥ शिथुभुभरोभुभ्रभदगाजीकुकंभलो ॥ ग्रठल्दपदुविकहृ ॥
मदमुड्डेडमारदि ॥ मृदगाभृडिकाविद्रदुवहील्होविमारदे ॥ ॥ णदुः ॥
हृभिवटक्षुरणउद्भृणक्कयउवतिः ॥ पदरगम्भ्रभानम्भ्रविवणेवीप
ठोमडे ॥ पतितिइल्लियडरःमापायाभुपग्रदक ॥ वनुकंहमगंमडः ॥
पीमृणिभुमभाण्यः ॥ मृदमभजगरीवाकतियमाम्भ्रमभाण्यः ॥ दमेघरु
दृगवनुमृहृनहृदिविनभुर ॥ माफुरयायिति ॥ दिमोधुदउमृधवरु
र ॥ विषुविद्धेमदृमभिपरिद्धदुविलवतिः ॥ यिपिविणर ॥ दवाधिरु
लिणिभुाजगमर ॥ वदुवदुेपादिउपिभुदद्मभरदपाधिम ॥ दमनमवि

पृ.
कि.

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

उपेश्रृद्दश्रृद्गविभूषिस्थपतिः ॥ उद्गदर्भमद्गिभार्यां श्रुमम्भोकापिगाश्रूतम ॥
शुऊष्णकं श्रुतीवापल्लवगाधूपयराजकम ॥ स्फूर्जं लास्कन्ध स्म सूरिभूग ।
वृयवश्नुपि ॥ श्रृक्कीलीनंल्लेकवादेयश्नुपस्नुदिपक्षिश्रम ॥ श्रृगद्रुह्नं नि
मद्वल्लवरठैदश्रृयैणारे ॥ पवकमेश्रिउँऊरांश्रुतीदद्रुवपिदवरम ॥
उदुम्बरं पीतफर्वेश्रमश्रिनश्रुद्गमपिम ॥ हृदुगं शुद्धिंगैठमविरिणमल्ल
पिम ॥ मारल्लिमउअंश्रुत्तीगडेद्रुश्चपपादं ॥ त्रिवत्रुगपुकवल्लशद्दृ
मुममाणनम ॥ विड्गुंवैंरश्रुद्रोदनेश्माद्लपिम ॥ हृमवंविपादि ।
हंमद्रुपकभणक्वैपल्ल ॥ पक्कद्विल्लेश्रिकिकृल्कुंउद्हंमधूलीयमि ॥
डिबिठद्रुकलपवश्नुनेश्ककरूश्रवि ॥ पकद्गुहकेपीनेमषांम
द्रुउ्रउे ॥ भूणवंपगभान्नाणीः ॥ भूहुवं शद्विमिद्रुयैः ॥ भुभ्रअंभ्रषद्रल
यैश्रिणंकूलगामयैः ॥ द्रुनंगद्रुनाक्कवंवद्द्रुद्रुदभूमाल्यैः ॥ गटद ।
द्रुदद्वितृदुठवाणुमाद्रुषमतुष्ददे ॥ मत्रिवमेममंभुगंलक्काभिदृ ।
भूणनयैः ॥ श्रुञ्जुदनेअंविणनमुपवाचलभिद्रुठ ॥ श्रुगणंभाणश्नुट ।
द्रुवाभुडेषल्लपिम ॥ नणिश्रुगंमद्रुपवभूदुवाश्चानश्नुपि ॥ यंश्रुए
तिमश्नुपिवंमलिलकनने ॥ उलिवंविरल्लेभुकेवामूलिक्कुभुषिडुप ।
ममाणामुममंकश्रूःपिडुगोपलश्रुमके दीवदूगावुनणद्रुवागि ।
मुशेउगश्निगी ॥ वणिपवेपुगद्रुद्रुठिग्रुमुश्रापन्नुडावपि ॥ लाश्रुद्रुमा

क्रिगायद्रुयामगाद्रुद्रुमाभनम ॥ विणनमवूमानेपिमाऊवानुषिके ।

णी कक्षूपणेपिकीपीअं नानापमिपिवेफ्ना ॥ ह्नअंवलेजठेहंम

एनीफ्रैपिलाक्रुनम ॥ ~ पाजुः ~ कलापक्रुषलेवदक्रलीगिमंद

उपिम ॥ परिस्कुमेपरीवायः पद्भुमेलिलम्फिडो गेपत्रेषुपाग्निपो ॥

दवविष्कुक्वषाकयी ॥ वाध्दवुप्रमूकमिभद्भनमाङ्कुडयम ॥ उल्दं

मफ्राकुमनेमुभ्रुमुपिविलेपेस्मियाम ॥ धाउऊपमऊपाठिक्रपावण

मरेल्लुयेः ॥ ठहूलिक्रुषभीक्रुमीवीभ्रठेमम्नकक्कुपी ऊउपेम्हगरे

मेऊपएमाक्रुषुमेमके ~ वाजुः ~ मजुगाठेवमङ्कुम्नगवुवेमि

हूनायनं ॥ कम्बुनावलयेमङ्गुङ्गिलिक्रोमपद्मुमके ॥ प्रवेहूलिङ्गम्पूरे ॥

माद्दथुंवक्रहूपिप्रवरभा ॥ मिथूमङ्गपिकद्मुविञ्चुङ्गिडएकेके ॥ ग

वीठजुपिविमुभूीमकुलेमाजुडोठले ~ ठजाः ऊम्हेमएठेमवं

मोङ्गिम्हेडुमिनुवालिमो ॥ मठेनुमुएशेठवोमकुरुक्रुशिलेमगे ॥

क्रक्विङ्गप्रठकगाङ्कविमुम्ठपूल्लयेपिम ॥ भाम्दहंदमठिःयंमिमा ॥

दक्कोदमठिम्भियाम ॥ भाम्दवएनेक्लीवंऊमभंकवकेयभाग

क्रइयेपिमनाठिनामनठिगविमम्भियाम ॥ मठमुभामिमङ्गेषुङ्गिम्न

ङक्कोपिवल्लनठः ॥ कुनठेकरपाभूमुवेविठेहूलेमभोङ्कषु ~ भाजुः ~

किवल्पूमुडेरमोकपिठकोम्प्लवक्रमो ॥ डम्कुमनेठवोकमोमक्रु

हूगोपमक्रुमो ॥ णमयहूयमठायम्रकवाम्रारमेभुपाः ॥ उपायप्रव

प्रगङ्कउपणाम्राभ्रूपरमः ॥ वल्जिकमपेवंवङ्गविरामेमानागवेलिक ॥

रिंगमेद्रोत्खले ॥ गर्भोसीलमाकमिडेरिव ॥ मकलदिप्रवेक्षलिप्तिगृभः क्र
ड्रोमविहृभः ॥ सुमेमुरिष्टरक्षमेलिन्द्रमुकुत्पिलेलस ॥ उष्णुपिप्पमद्वेषु
लङ्कारेङ्गोमविक्रमः ॥ गुल्मेनक्षुग्नमेनाद्वएभिमुवन्तुलनिपुः फि
विक्षुः क्षमायुगेक्षमंसाद्गेदिरिव ॥ सिघ्नमभेदारिक्ष्वेमुभामु
क्षविवाविमा ॥ ललाभंयक्षयञ्जुषक्षुधांशुणष्टकेउष ॥ प्रक्रमष्टम
मूपादेपूर्णमेपुषमसिव ॥ वाभोवल्लुषुडीपोमावाणभोपुवक्लुहिमे ॥
णीर्तुंन्मपरिकुकमयाडयाभमिमुंतुपभ ॥ हमेग्रकडक्षनङ्भृणि
वाम्बुविविनमः ॥ सूभोप्रभाक्षकेनीभानद्धनीवल्लपाङवः ॥ याद्गः
डवक्षणकनेडक्षेविलयापूमयोक्षयो ॥ श्रांमुदेदेवरमूलोद्गमष्टी ॥
हक्षलोद्विधो ॥ मृलशेरनमदरक्षुमादनक्षुमिवैमृयः ॥ सिपृष्टमूकलि
मृगोपदर्यवमरुनि ॥ मृदयुणीरमयबक्षांविमुमगडेउम ॥ रज्जूमवी ॥
मागुमयेनीडद्वेपाडडपयः ॥ कुलेश्वयभुमाकल्लेमागानांमष्टमणडे ॥
ममयाद्वपपाकारकलमिडुडमंविडः ॥ हमनाहमुठंदेवंविपाडिट
नयामूयः ॥ पाहृयेगिक्रमनक्षुडेवक्रुरेधूणापक्ति ॥ यमुपष्टेम्रुम
गयः ॥ प्रष्टमुक्षुवगपिम ॥ पक्षामवर्णपिरलंसमवायमभृत्रयः ॥ म
क्षुडेमविवेमममंप्रायपूर्लयाप्लुगी ॥ विमक्षयाक्षुपूमंल्लविरणेपि
ममक्षुयः ॥ विमयेयमृयेक्षडमुडमक्षाडिकेवृपि ॥ सिदामपिकया
पु. के. येभ्रीशरक्षलयांमुरिमुयः ॥ भृयेक्षमृतुगमनेभडमेरकूडेकृणि ॥

गन्धेभृङ्गयोर्गुहं अहं समपवडपद्वयोः वीदं वलं भूकथ स्रुमुहं कर्हेयु
श्रमूर्ये पिङ्कं अगे दे कग्रोक्ता शंकमन्तुकब्रकम् | कमेन्दद्रोता
इंयंविमन्नाहञ्जिकपिम कपाकपायीम्रीगोदेत्र[illegible]नामनेकयेः ||
ब्रम्हेतिम्रूतिक्तिमाभ्रणंमंभूणवल्लभा | उपायकर्मस्वभूषामि
क्रिमानवस्त्रिया कयाश्रदश्रियाकतिःभुतिविभ्रमनाडपंः कश्रीयु
केशुदकूः कन्तुमहकवनुं | न्दहस्त्रियादेवडयेस्मिषकहणामि
तिः एणम्नुल्लनवारुपिएणमहङ्क्रणमदिम | मान्दणीसेनवडर्ह ||
कलोमल्लतिनामयो | प्रमवानापद्ङ्रामसहोषदं [illegible]मावपि | कहंम
मगुरुपपिवमदंवन्नुमागपि | तृयपिमहन्मृहमेहभमद्रमौद्भवडं ||
मवल्लत्रियरोवेहीकरुल्लाफल्लनवहस्मदरिडं | कलकल्लालमयक्षहंये
गृंभान्तुतिकौतुम् | कयामगडिक्रमपिणलनम्नरूपिमासंयः | दिंहमा
हपिण्डिमाकवायम्कनवतिं | उद्भिदयोविकवपिमा[illegible]प्रार्थेत्रयं
मृडो | मीडस्त्रिडाश्रिंडस्त्रिहंएणहंरुललणकडयेः | हवायेहविकेवह
ममकमपञ्जुकस्तयो || ~ गाङ्गः ~ विवदवमयेवधोमंशुमेभम्
गाण्डवे | गुरुणीधडिपिशद्देहेद्रवेयोसुवगांमयो | क्रकवेनेहममानहं ||
प्रुकगाविद्रिङ्घ्यजडी | किंमाङ्गणदंम्कस्कवश्वमभुणवणपो | पद्रन्मे |
प्रमनैल्कः भृमुवाहुपवेगो | प्रमुविव्दवावह्मवलिदवामे |
वक्कुराः || भूदनहतमवीदमाश्रमदक्तमावपि || मरुउमदङ्गीमिकले |

धुम्मसुद्धामयुवरी॥ सल्लुमिगंःपरिकरःपदकुपरिवारयेः॥ भक्तसुहुम
उरसूक्ककरवायामयुहिय॥ कम्ररेसुयुग्गिललिअंविसयपमसूकरः॥ व
मकहदगुभिवाहमइमिइरवावपि॥ भायपुत्तुयमरुपिसुमत्तुहुत्व
सुकरः॥ पकुमकरमुदरवगालमुग्गमगलिडे॥ पकिदवठियगापिठंद।
भवदवेपिम॥ सुल्लदमेपरीवारःपइणकमेपरिसुकुमे॥ विंमिसुविल्ली।
मठपत्थिपीव्वहूमाणवम॥ सुगिसुमहुपडीजरःपडीजदपूनउर वि
पुलेसकलेविसीवरुसूपसिमलेडिय॥ भारेवलेमिसमाठमटायवलोवं।
वराडिय॥ डरमिरविड्डकरपुलफुडेडरठिमम॥ भदराहमदनपमुकुम
रःधंवधंभकम॥ भमारेहगुलसुपडडकुपल्लयेमिय॥ मवाहुउवर।
सुमुहियक्कीवंभताक्किय॥ वरभूमरमवाकियभामलवठउरि॥ वंमा
डरकवीरभीडमठमभएमणा॥ जामगलपयरदमराइइमरविसुयाम॥
यमापिलसुमपदकविसुमिंदपुवालिय॥ मुकदिकपिठकयुदरि।
वाकपिलीडिय॥ मकराकपरांमपियाउग्गसूपरगीडे॥ उगाउवाकु
मसुमाउसीविदुपमीलयेः॥ णडीमाहपमाडुपिपिमिगिमइमलठ
पि॥ समहसमालीवसामरयाकठकरिक॥ भिमकुवणलदपिकठुं।
मुपलजीमयेः॥ भाग्गपरिसुमेलदमयपरिभालवणवल॥ सुल्लाहग्ग
दयेविग्गिंकलंइसुलिठदयेः॥ गलीकुलाडुरयह्लठदसाहहरकडरि।
यिहठणयेः पाइंधइंवाहजयमायेः॥ तिमिमयुकुयेमंगाधुमसुभावण।

पु. ३६

लिदयेः भूपल्लएंसुकयइइक्रोइंपङ्गीमवीरयेः भापाणूहूंदलयाः
पेइंगामूंउ गाश्रिम मइभाम्कुमदेयल्लेमदृमावेणेपिम ग्वलिइंवि
घयेकायेभूथ्वइंहेश्रिवाभमि मइंगाधू भूक्रोइंउ भिक्रोपिक्षीवमन्हम
थ्वक्रुपिक्रुविमद्देद्रेम्ववभाइपिंगीपवमं गुदमद्धोगाक्रुवद्वेवंदेउि
कमुपक्कुव पशंठिकमुपदगूहथासेसणावेप्रवमं मदिवंसाषवा
धूंसूीविषयेशाद्रुपदूव मवेमिूयांठवस्वहबल्लेभूदीयकंपवो
उयूंधूणनेमिहुउ्शइवायेपविम्कुमे क्रमीवंसाभवेमद्दईसूीवंम
यगाभवे पथ्कुवंकुविदभागूवाहुठंन्दभापिएल्ले हूँश्रिपम्कन्हल्ले
पद्म गिंजोधुणिविमषयेः ~ पइवमवकामवणिपविणाइथिंठ
मडामक्रुम्स्मिमूमीयविनावदिवमवभइहउगाम्नविम ~ थ्वंउपि
पिठिवंगालोकमेक्रहपिनागवमें मावसमउउभसेयाउकुक्रोइल्लि
न्हकः गोवेक्लम्सिउभीउबूम्कवथूकक्कुवः णान्वःपिठिवेपिमु
मणभाममुपिमाणवः ग्वगाकुल्लेपिमेकुणूहूगेहूमजठक्रोलु उपइ
मीषूमूधुथ्वथूउइंभूगमदउवः गंथावियदयेमूथ्वु डगाभादउभाःपवा
भ्वाक्षुथ्रूयोइमपवोउठेकणिनिदियो उल्लेवेमदमदडेविउवमूथूहूबी
मयेः भमम्वक्कुदयेभूंवःभुइभाधीयमूक्रूयेः ठथ्वक्कवलयेक्कुवंदम
दिइउवम्नयेः धुभावेगवक्कषमंदभावल्वउषा णगाम्वपाइमेक्कु
क्वमोकछदेपिक्रूयवः वधुवंभमवेभमिविनेम्हकमेल्लयेः मकभाल्लुं

दविध्यजुवणीयक्कउयमलि ~ लागुः ~ पुष्पकिसीएंकेमाष्ठम
यउभेलियमुयः पूमधूकिमभाय्यष्ककधुखष्यलिपिलयॅः जङ्गुर्ने
दमेक्रलः मउज्ञपियगकलिः भाकुयक्तपिकलमः धूर्वावपिसक
भलः करेधुदययेः धंमिवलि श्रीरुपलेमियां औल्लुमामद्गमे
थेधूवलनाककमीविलिः वधुलः धंमिवाहुयाभयंवाय्यमदेइघ
ठहूलिक्षमेंशलःधंमिमुायदमथयेः मलेभीयापाविक्किङ्कुट
भीमुकुलफर्गयुणभ मक्कवपिद्रुयेक्कीलः पालिः भूमुकुपाक्रिघ
कलामिलेकलठेमीलीभापृवलीपयि पमृमुविकृडेवला
कलेःपदमयेरपि वफलाः लडिकामावेरफलेग्रिभ्रिडेइघ ली
लपविलाभहियये डपलामककृगपिम मेलिड्मुभिकीलालंप्रल
माहूमिछठयेः एलंमप्रजमुायेगवाकाजरकवपि मीलप्रठ
वेमहडुंमपृजेडवडेडलम कटिवेहूमलेत्रीवेमप्रडेपएलंनरा
घणमुकुपयेरश्रीउलंभाषाभिधिपलम भयामलेपिपाउालेम
लंवमूणभेमिघ जक्कलमकुकिक्कीलूमुहशाउडुपालल विलीडे
कुवलमिडिशिलिकंडकलक्कुयेः पहुघिकेमथएथकुमलंमि
भिडेइघ भुवालमकुरेपश्रीइघमुलंलाडयिम कलेमुउवे
उमुमावेरकपिपिमलः प्रलेडुकपिवालभूलेलम्बलमम
थूयेः कलंगदयिडुलाकेऊवेरमेककडलंे भीदवावकुयेडला

पृ. के.

सकलसुकृयकलभं ॥ कुलिशिखिपिकुलमलाकाकुलमपूयैः ॥
दृभलंहृकलेसकेसधूलीकलयालूपि ~ वागुः ~ ठवकवेष
नागरूवकीलमदनठवी ॥ मधुमदयस्मिवोपशिमापिरागवाः ॥
घवयसुंलभेयाकपुष्कलापुगदवाः ॥ ठवमतुरुठवाठिशयम
धुमलमम ॥ शूदयदलेषधेपभवेगाठभेमरे ॥ चविश्राभेपकर्ण ॥
पिविन्तुवपिनिकवः ॥ उमकमधयेरिसुधपभवेमदउसवः ॥ चत्र
ठवः पूठवेनसतुगमतिविसय ॥ शूलमदेउरेठवः क्रांमाटेपलतु
य ॥ सर्वेठठमेक्लीवंउनिशुयेमाश्वउद्भेष ॥ श्रेष्ठगवामनिश्रुंरिश्राम
येभेश्रियांणने ॥ श्रीकणीवसुरतुपिनोवीपरियल्लपिस ॥ सिवामोमेठ
रवयैःद्रुमकलदयुगदयैः ॥ दृष्टाभटवमायेपिसद्रुमश्रीउलतुष ॥
गुलवलेश्वठवैमभावेसदृमूलाठयैः ॥ क्लीवेरधंमकेसठवायिनि
द्रुमविरुम ॥ पटइगाशिमूलजोधूष्टोधूष्टंमरतुरुभ ॥ शूमणवर
उेलक्ष्ककविसुरुकुवीमयैः ~ मातृः ~ द्रुविमोवेदृसशलेद्रु
मागाठिमुरोस्दमी ॥ द्रोगमीधरुमेषाद्रोद्रुवंमोकलभस्कुरो ॥ गजरे
कमोधोकमोनिवेमेघगिठेगयैः ॥ नागाउंधंसिकीभामःश्रदकधक
योभूष ॥ पद्वविभिदुयदमः ॥ शाकुमभदुसकमा ॥ वभावकविणाटा ॥
मामधुपिमायउवमाश्रीकरिलीनसूदमरुकंकउगिइष ॥ शूफक
मभदमिकः कंठोभमवरवपि ॥ रुकमोउधूमिद्रुपिमिमावल्लम
दिगदिदन्तयवंय कुदिउद्रुदमंविदुः ॥

110

वालिमः नामःकयोडिरेणनेल्लौविडमःश्रियेयम ॥ हनंमापङ्क्रिनि
भिमावंसश्रुद्रंमवङ्कुरः श्रुह्वाह्रामालिमीधूञ्जपामेवड्डरमभु
येःलक्ष्म ॥ पशुडेगद्धपामेनकेमपामेनच्छवुडः पाखुयेकेल
पामेननवडेवद्दनंमियाः ॥ पाडुः ॥ मवमस्नृवतिमिवीधन
धावाद्मभानवो ॥ ककमहृद्धगोश्रृंद्धकमोमद्ध्मवीनणो ॥ पुंनीयु
धूगुदेवस्मेधूवधूवल्मभद्ररे ॥ गनेकलेपडूमनमोपानुविकलि
ड पत्रासमदयधूकुलीयःमिस्वेयुकिरीएये ॥ मुवलेश्रधकेमृसु
मरुडेवपत्रेवधः ॥ कपेश्रीञ्जद्दुलेपद्मपिणरेञ्जोप्पमिद्दयेः ड्रुडे
कोमनविद्धलकेथाकवेणाकृमिद्भिय ॥ गाङुड्डकेघमकूरूपदर्के
लिङ्गूम ॥ कड्रवाङ्कलीवापिःकड्डकृल्लाङ्लिणयिनी ॥ धरुयडङ्गियायं
मधीनधंविषमञ्जम ॥ उपदनेश्राभिमंश्रुदूपगणेपिकिम्बिधं ॥ शृद्धि
धुलीकणडंमेवडदेवधमसियाम ॥ प्रजजड्कल्मथुद्धकिग्नमेवा
ज्जाद्धतिः डिङ्क्लिघिपिडिश्वपवेदकेकरनिमश्नुयेः ॥ शृडमोणिनडेहमे
ड्रमाम्रधूमुपिकाल्ल ॥ दलगमद्दमवहुवलङ्कंप्यथेधवधूल ॥ कुपि
मीधंकिडिमन्हेनडधम्रुवकमद्ग ॥ दिधेवाङ्गीकिदेवावडेमकीपि
गङ्गाणः ॥ मृगनूणगगड्डभाद्भयेश्रुभापश्रवाल ॥ भाग्नः ॥
गविश्वेडमकृदेदमोश्रदवतीविकवम्र ॥ वर्मडन्कवदेवैमावद्न
पु. मिग्निवीकंमः ॥ मद्द्वाडेविषवीदगुलमानमृवेवमः ॥ यंशूडंमाव
के.

डूंसोवाकलुपुरीपिसापरं ॥ सेवकनिलेरमोवंगुरडूणविवम ॥
विक्षेमवंणस्रीसमीदिडामभादिमक्षुयैः ॥ लालमेपुणोद्रुहे ॥
डिंभासोदालिकमम ॥ पुत्रस्त्रापिक्षद्वीरोरेमस्रोरैमीमरे ॥ डुला
कमेन्वखंसूविलेडिक्ष्ठद्वमद्युवि ॥ पंथापवाणयैराः ॥ पगडालु
णिनिंवयः ॥ डेला:प्रीषयैवम्भदस्निमवडेलमेः ॥ गएगुलमस्त्री
पक्षैतादिस्राडेगुलडमः ॥ कमः पसुकिलावमडपलक्ष्मलिकमम ॥
मदेवलंभदभाजेनठक्षिमूवालेठः ॥ तकम्नम्नमूयत्रीकःपयः
सीरंपयैस्तुम ॥ तएमीपुवलेसुडक्षियैविप्रगायय ॥ डेलाःपठ
वमीपुसवलेमुक्तेष्टुडसुवि ॥ विस्रविमस्रठीठसेदिनेषुडिमयै ॥
छमी कक्षुखमष्टयैहुयाकीयंपुपवाल्दयैः ॥ वरीयांभुक्रवरयैः ॥
माणीयामपुवालठयैः ~ दपुः ~ मलेपिवदेनिक्षुपुरागा ॥
क्रमयैगूदः ॥ सुदपीडकाघरमेविडुदेणगमडके ॥ डुलापुडखापि
गमेपुगदेपुगदेपिम ॥ पसीपरिएमादचभलमापाःपरिगूदः ॥
दरेवमगदः मूर्तमघृदेवगसुियः ॥ सुदेक्षदेपूदिवक्षेश्यापी
क्षमेपदः ॥ परिमुक्तेणपादेजेपरीयदेश्यः पर ॥ ३। ४१० ॥
भाभाहकस्पात्कपनमुगीयः ॥ ॥ तिपुलीपमजठिस्पो
सीभाजेणडुयैगाएं ॥ पुयगहःमठेवाक्षेभुराक्षेपपीदयैः ॥
पापकमेमसजेणिखिठद्वनविमयैः ॥ संज्ञामयमभादाडेरडर

[illegible]

पुष्पिताग्रमध्यादिषु

विश्लोकानयमध्यमनः

समस्तपये ॥ सुग्रमी: कमपश्च पुष्कलस्थितिः ॥ स्थिरप्रविव

कुम्भं सुकन्दवरणयाम् ॥ मनः मक्कवायमपूरान्तरमभीपयः ॥ स

नीमुंसरमपन्नासरूपकविकल्पयः ॥ प्रपिः समस्तपरवरेवापक

मुरीपिम ॥ वनः मन्दमयः मस्तमन्मस्तकस्तयः ॥ पिमदरकमदमन्त्र

षविमदयामन्तस्थित ॥ दसदवकमदयावासरम्भविवादरप्रेः ॥ ति

दशमकालमुकर्वधिसमभातिष ॥ पूर्वंशरभूमयवनमप्रागतं

द्वपि ॥ यावत्पमप्रभाकलवर्णभानवणाल ॥ मकलानपुरागस्य

सकर्मधपवंध ॥ वधाविरजकाविवाद्यारकव्याजयः ॥ गंधस्कृयाम् ॥

विकल्पमपन्नाक्ष्मस्वपयरं ॥ स्वावणसम्रकृतरयामस्तवर ॥

गदसमप्रयरस्वमक्षमथवादपिं ॥ उपमायांविकल्पवांसांमि ॥

दूतलगुणिद ॥ समासदममीपमक्वाविलिमयशपिग ॥ ऽवक्रम

अयरसंत्रंउक्काविप्लवे ॥ भूमाणतजकंत्ररमवस्त्रुविश्वयमयम ॥

मंवद्वयरत्तवागामवंस्वयमाद्रा ॥ पल्वतीमंमदद्वः प्रयेक

भूतमरः ॥ मतानिहरवंदिवरक्ष्मपीदुभुमरूकार ॥ पश्चिमहकर्षु

मतुक्तवप्तरयदपि ॥ उक्कभिन्नरूपरपदरवभायभरेत ॥ भयरज ॥

क्रतिदयांस्प्रमषुधर्मंमर ॥ मायेमायभूगपाउः धत्रविकयातिक ॥

पमद्रनरहंसमद्वपेवरवदरयति ॥ पदृतद्रूपमप्रवेळीहमेयवेउ

गपगत ॥ उवाणगरगउरउरगवहरमयः ॥ उठयांकाक्रुयद्दः पा ॥

प्रवमित्रदरिप्रवह्नः पंउक्वहः पूगहः स्वरहः पूरउहः उगहः पयाहः

क्लीबेऽपि स्युरिति ॥ ह्रीं ... परस्त्वपरं इति, उपदत्तमी

यथापदेकमसवक्तमद ... ॥ ...

लिङ्गमक्लीबं सर्वादि ... ~ षष्ठवर्गः ~

सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः । अनुक्तैः संग्रहे लिङ्गं

संकीर्णवदिहोन्नयेत् ॥ लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ।

स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च । नाम विद्युन्निशावल्ली

वीणादिग्भूनदीह्रियाम् ॥ अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ।

तल्वृन्दे येनिकट्यत्र वरसेनासुरादिवत् ॥ भूमिवाच्यस्ति ... लल्

... यलोपमकः ... पिण्डिदिक्कोणदिकपलानं ... ॥ ...

स्यादप्सरावलिम्नोषापाल्लवल्लि ... प्राग्भागेभ्यः प्रियादिभ्यः ...

पाराद्दिक्व ... पत्र्यभगयलं पार्णिका ॥ ...

... विवक्षापमदरया ॥ लक्ष्मीदात्तिकालेकारण

कीयत्विकात्तकी ॥ सिद्धिकामातिकदिका ॥ भूमिकेत्तुपिपीलिका

... कीकाकलिकाक्षितिपनक्षत्रतिथ्यादयः । पिपिक्काविडङ्गकादि

... प्रतिशुचीसूतीदण्ड ॥ आविकन्तदण्डायमश्लोकाकीचानामण

पित पल्लवीमस्तुपीयायीदिवस्वहृषभिमल्ला ॥ लाक्षालिकस्याग

दुषाद्धत्तोरानमनीमनी ~ स्त्रीलिङ्गविभेषः ~ पुंल्लिङ्गम्

इन्द्रमरुतः स्वपयायाद्वपास्तत् ॥ स्तनयागाद्रिमध्यादिपदकाला ॥

[illegible]

[illegible]

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ॥ कण्ठीरवो मृगरिपुर्मृगदृष्टिर्मृगाशनः ॥ पुण्डरीकः पञ्चनखश्चित्रकायमृगद्विषः ॥ शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ॥ दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ॥ मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ॥ लुलापो महिषो वाहद्विषत्कासरसैरिभाः ॥ स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ॥ शृगालवञ्चकक्रोष्टुफेरुफेलवजम्बुकाः ॥ ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ॥ त्रयो गौधेरगौधारगौधेया गोधात्मजे ॥ श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् ॥ वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ॥ मृगे कुरङ्गवातायुहरिणाजिनयोनयः ॥ ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ कदली कन्दली चीनश्चमूरुप्रियकावपि ॥ समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ कृष्णसारो रुरुन्यङ्कुरङ्कुशम्बररौहिषाः ॥ गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ गन्धर्वः शरभो रामः सृमरो गवयः शशः ॥ इत्यादयश्च ॥

[illegible]

[illegible]

पाग्रहदत्तुरकाजद्विगल्लमृगभारउः॥ द्रुवकशहयीकवोपवमृ

हिहयोयुरः ~ मधुस्रुयावकम्बेमेदकोमसूकाभिवा॥ मालाग

पिपरागणेमखमूजगुरालकुउ। गमीमठंतपमठंसकसूरुकमि

मानिसमः। उपलेधमसमत्नोसुउमलितुपकमरे। कैपल्कैयसूमा

लिकरूमीनरनामम। कवैत। लकमिहुहैमधदेउवकमल्लः उम॥

रुपूहयापै दमविनामांपसैदः। क्रियाहयांगठमकाटूकरै

जुडेकै। मिमंमुजगदम्के लिकिरीएंभमयोलनै। गलप्रयंवाए

पर्यंगहपहरिककवः ~ मालिकृठमूमिडरमीरमीवरपक्करी

लकायडंदतितालं विमलमुलवाद्रुकम॥ ~ ~ गंभकलिक्षपि

मेषः ~ ~ भैरभेमकयप्रुर्यायुवः पिल्टकककगुकः। मेठकैस्रु

कुकधुकःमाल्कैक्षचवरमुवः पाउकमुगारामककउभालामलक

वऽः अँभुमॐमीपरमोक्षाडिकमजडुभभ। मकमंमडभागा

ऊमखलाहयगाडवम। कृवियकठकथमं। पामवांशमगरुरमे

प्रयभुगीवपाशीवं प्रुपमगमयिकाभी। पुवयंगेयकडपडीनोयेसू

मूवेतिकंएवम। उवेक्रुभिदलकभिमसूडफुमुमेषवज ~ ~

पस्रभेमकलिक्षुविभेदः ~ ~ भीपंभयीरपहगडिमडबद

दवगाः [illegible] ~ भीपंलिक्षविभेदः ~ ~ द्रुपेठवयपेफु

मिक्षपकुकीडिऊः। उमिहसोमिसीमेङ्गु मंहीवुफुपमदहउः॥

[illegible]

यमूतुधक्कुलम्भ्रनाङ्कयामालानन्तरितमाः श्रीकृष्णमैत्रंब्रतिसंगीमा

लभिङरमृमिक। श्रवब्रुतुङयपङिद्विगुन्नांधमिव ब्रलप। शिपद्वं।

यशिपद्वीरसिङ्कर्ङ्गसिङ्कृपि ॥ श्रीनरंभकलिङ्गविसेवः ॥ ॥

शिखपाशीपलीकाली ङनवृरूदिस्मिमयः ॥ पनलिङ्गप्रपूणारेद्विम्नु

मृगवपिङङ। यगङ्गाभूहलनशाम्भापवप्रवापरेपगाः। ङमिङगङ्गि

गुम्मक्तिः मवप्राङ्कुङमत्रकः। यरजम्भमसिङ्गथ्राम्नुत्रेयाङमनसङिः।

गुम्महतद्रियापेगापुणिठिपेरगाभिनः गङकुङवमंङ्गपांकरो

कृङिकमनि। यत्रहुत्रामुनरस्प्रहृतोमाजठेमकः ॥ यङ्गंहु

कमिथुमभायप्रम्नप्ङ्गुलहूयम। पंगविरेणमयंङुत्सूयंमिथु

भूपिगाङः ॥ ॥ ङहभाकिमिभाभाहूकच्छलिङ्गमक्रूजवजः ॥

ब्रगङिकशङ्कुकरेभूहकंदमवनङः आभाहूकच्छपङ्गनेकेमंठ

मरमिंदकम। ॥ ॥ ॥ ॥

पं
कं

[illegible]

ब्रनयैरेत्तुगडिष्ठुठे चतुराहूंसमांसकमच्छल: ॰च्छलचुद्रमलमडरे॰ग्डिडञ्जलञ्ञमरपेद्वयं

छिथानुरेतुना । चतुरे॰मभहेष्ठुं: ष्ठुमहृडदणजकमं । यक्रेद्वमांम्हडेभ्रुं ।

दरीक्कुमञ्चमदनारउ । चठयेनहन्देनोपिमांम्दमांलंमवरुं॰ । यक्रुडेमञ ।

हृदिमडक्रुहृक्रुक्रुमाङ्रयम । ष्ठकहृष्टृदंरविंःष्ट्रादिमवंपरमंमड ।

ममनुडमुपरिउःमवडेविञ्चगिहृपि ब्रकुमाडमडेकमंमुद्रयपग

मभुम । नञमभृजिरेणक्रोकञ्चिकुमष्ठुवेदन । निःममंदःममंगहृ ।

यणांभ्रुंडुयणायुंघम । मच्चांमिंघ्राडुविडघयघजंडुयघाडघम । ष्ठुर ।

वंडुभनवेवहृवणर॰वांमकः ष्ठुगडीजक्रकंञनमवम्हृंनिञ्चयेद्वयम ।

मंवडद्धवरेडवागामवंभ्रयमाम्हना चन्दीमेंदनहृञ्जेभ्रायेक्कमृहृडेम

नेः मनामिदेवडिनहृम्हगीरुमुमदमवन चञिमक्षुगयेक्रयप्रंश्रश्रगय

हृयि उकेश्रिकृद्भयागाहृरवयमानेनमेनेडो भनरक्रेक्ननिदयांदञ्जुमञ्जुप

मंमन मायंमायद्धगंशाउःपृठउनिकमात्रिक यदद्वनाहेघमिंडप्रव

प्रवडरेयति चहूर

[illegible]

ॐ नमः सरस्वत्यै ॥ ॐ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

फुल्लवः [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

वपिपि लपभानमे मपमाङ्गरे मपममवाये रपलपष्टङ्गयांवा

खि मुपमङ्गयांगङ्गे ङ्गप ङ्गम्द ङ्गप ङ्गम्द ङ्गङ ङ्गम्ढ दिंभाङ्गाः

पधरढरक्षि मवपव लव वष भवकवापवगाव मवखव

मववगाङ्गे ङ्गवि पुकाद्गने लषि ङ्गषि पमने मुषि वङ्गअंयेग

मूङ मूङु दिंभाङ्गे भङठवल दिभाङ्गेम गुपादयङ्गङ

गाङ्गदङ्गङः पिलि पालि पठलि गुदलि पुल पुलङम

ल पलष्टवङ्गरमुङ्गेम पनम ङ्गमङ्गृणि कापथाभदने कम

कङ्गे पङ्गगदयङ्गङ्गाङ्गदङ्गङः पुलरलवलठलमालकुल

ङ्गालङ्गलपुलमङ्गङः पिङ्गपपनयने मेङ्गवलगाङ्गः मु

ङ्गमंध्याङ्ग पेङ्गगाङ्ग ङ्गरलत्रिषलषु ङ्गलमङ्ग कामीषि

कङ्गिवरलगाङ्गिप पुरालमङ्ग वरपलमङ्गी पमगाङ्गा

ङ्गिषु मूमदम्दमीमङ्गगाङ्गे ममकमलमलमरम पमने ङ्गमप

मविङ्गपु ङ्गदङ्गु ङ्गदङ्गङः पयवयपयमयमयङ्गयलय

गङ्गि ङ्गयरङ्गलम दयदनगाङ्गि रङ्गलदरेष रयगाङ्गे ङ्गयी

ङ्गुमङ्गाने प्रयीविमरलदनङ्गुम ङ्गयीमङ्ग ङ्गदनेम ङ्गयी

ग. विपुनरे मङ्गयी पिष्टयीषङ्गु ङ्गपप मङ्गानपालनयेः मल

पा. मलनमंवरलये: वलवल्ल मंवरलमङ्गुरलम मलमल्ल

३

[illegible]

[illegible] १२६

लिखितविलिखितविधौ ... राजः त्रिविधविणविगद्दगः दविदिंमाकर ...

येषु मधवतुते प्रधरम ... गाडिकति भीतिरु ... वगभार वेम ... श्री

भूगयाभव क्रियेषु ... वाणालिक्ष्म ... रकवक्रतिषु मध्यामय

रुद्रनु उदरेऽः ... उदरः ... पकाणिकमनीय

नन्नामनवलीवनेषु ... मिकविदूपादेन ... यासूयाम

लाकेलाकेय ... मायांबामि ... मोधूजेम मीक्षमोहु

...पनयवद्दमेषु ... गतिदिंमागाति ... नेषु

... यांबामि ... गाध ... विकुयाम ... लेधूरु

... मके ... कामलमदरु ... याम ...

मीधो ... मको ... मुरः मामुः ... यां

... याम ... शिदि ... गद ...

उत्तमयाम वदवल ... पण ... पनिकप ... माकुर नेषु श्रि

दगौ वहलीह ... विद्याकय कामलमीधो ... विडके

गाकविलीजे ... प्रलय ... अधिकतिकर ... प्रपन्न

दत्तः ... अधिग्र प्रविमूढने ... मडळउम

उक्त ... उक्ते ... पालने ... उक्त

दूक्ता ... कगौ वकवे ... मडळउम मक्षमळुउ उक्त ... गधी

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

१२९

छन्दप्रयोगाः।

मध्ये छन्दप्रयोगाः [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

समपदमतो दृष्येदृल्ले मध्यदधुमेडवयः दृढलिणां मायाम्

भृदवैमिहृ क्षुदउमिरल्ले क्षिदमोडि वउ मथउपमम उम

कक्षयां दमउपमम् मथउथलिपिदृम दृषयवभूले कमु

भदले ल्लेपप्राणो भैलीदद्य ममादयेषुगउः पुषुक्षेपल्ले

यषथयद्र लप्पमेम्रल्ले उम उपकय दमपदवमषमु दृषविठ

न क्षपृदन विमेषूरल्ले दममंग्रयल्ले वमउमूले भमापद्

र ममीपविमाल्ले ल्ल्०विल्लेदरे उममनवाय दृमुदृमु षणः पु

दुरे वपषयल्ले जमउत्रकल्ले लिद्घाधिपामायाम् दृषदु

हे दवविपदिमायाम् दिपमेपउपदृण गपदृक्तलदृ यप

दपल्लपविभिदरे लठ गान्तु केठमपल्ले ल्ल्ठदुकदिमायां

ल्लिदपुदीठवे लिमिदप्रदले लिक्षिदमृदजमेदयः

ल्लेदृ दपुपठिकल्लयाम् वउ दृउिदिवामय ः + भूमि

पठिपृवे भिमिवदुरे मिमिविमाले दुमिमिषक्षयल्ले मिमि

मये भूमिषुम्मले जामिदिमायाम् वलावल्ले प्रमिक

भले दुमृउपदय उउः मदृगसिए ः दिगउे वक्षुम पशीउ

मशीउियाल्लनये ः पल्लेदृदयेविदृयमुदमोटदृदः पुभृ

ण० दृपुो मक्षमञा गणणाणमंमिक्षी पषक्षवदपउउो षमु

पा० दृपुोमंपाडम क्षिप्य पमूदले पषामाप्राउदवमेपदिरः

३

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

१०

१५

२०

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥

[illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

[illegible]

स्वभयविस्त्रिधयेत् ॥ पूर्वाग्नं वल्कां विपदभञ्चविस्त्रिधं जद
त् वाल्लभेदभिन्नत्र्येवमन्त्रा ॥ मीत्रिजडे ॥ हूंक्रजनभस्त्र
यंपवंवल्कांनयेत् ॥ विगमदगभूंत्र्यइभा मैहरिः दणीदमा
मभ्रूदय: वेदधिः मीत्रदवल्लेपमव कुभागीयमा दत्र: ॥
पवंल्कुउवल्केय ॥ पकराकरेङकरंकरेमपरापकरःभूृ
त् परल्लेपत्र उवेदमा मेयमा उमेमः ॥ उंवल्केय ॥ प्र
वल्कुउवल्केपरापकरःभूत् परल्लेपत्र उवेदकमा गक्षिक
कमा उमेजडे ॥ टवंल्लेपग ॥ पवल्कुटवल्कुपरपग
भूत् परल्लेपत्र उवल्कुमा भक्षिः ॥ हवंल्केपला ॥ प
वल्काहवल्कुपरेपलाभूत् परल्लेपत्र मरेवाणः उवल्कु
रः ॥ फंकरेपिफकरेय ॥ पवल्कापकारेपिकरेमपरेप
करःभूत् परल्लेपत्र उमेधा मिवेन्द्रमा ॥ फंकरेफफ
करेम ॥ पवल्कापकरेफ्फकरेमपरेफ्फकरःभूत् परल्लेप
त्र उवेमदः दवेक्कहूमा ॥ उवल्कैंयभ् पवल्केगमपरे
लेघ्नः ॥ उवल्केभवल्केंत्रवेपरेयत्रभाप्रेजिपरम्नलेप्तन
मञ्जु नह्रेमा ॥ वभंवल्कुः ॥ उवल्केवभाप्रेजि पमवल्क
त्रवेपरे भञ्जु वम्राम्रा ॥ वभंवल्कुः ॥ टवल्केवभाप्र
कु॰ जि पमवल्केत्रवेपरे णडंमः पिङ्गः ॥ लंभूवल्कुः ॥
कौ॰ हवल्केलभाप्रेजि पमवल्केत्रवेलनवङ्गः ॥ मफिंदरःप
३

[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible] ॥
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible] ॥
[illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥
[illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥

[illegible]
[illegible]

ंषवङे ह्रियाषेनि
मटहहिविठेमवः
मुभांलिंमुह्रि
मुङम्दव‑यवनिअ
भिवाङेनेत्रिमटन
मटङेनेहद्रिषिपिः
षमूंङनभूङेवान
भाङयेनंलिङवमः

०३ नियतद्विमनविमुमुद्रेपुद्धद्वि नियाद्गः नग्निद्वयेमैहद्वयम्

पह्नाषडउमुनियाउः मुवेभनहट ॥ मडेभनहटःमूः
मुवे षदि षलं षष्पयेदि उउमुः उउभसः मुगवेंवमहस
मुगवेंवकिलउअ मुरुणहडे मुरंषदमूं दमूम ॥
०३ स्त्रिवमनभनी ॥ दकवबलंउअनुमंस्त्रिवमंउमा ष
ग्रीषह वाग्रुउन पमेङेउभो षनोकिम उविन ॥ ०३ वहू
वमनभमी ॥ षभीउडिवङवमंउमा षभी षमाः षभी
मुनिटः वङवमंकिम षष्टह ॥ ०३ षंयनिमुम ॥
मुउम्रउमा हमूपदि मुवामुडेमडिमुउहम मभुदिनि
मिकुकावकविवैदिक उडेवा मस्मैउडि मस्मविडि मभा
नटकेरम मेवठषिः मेवद्रिः ॥ उडिमुवमत्रिः ॥
०२ दिवलषषभाः पमतुाः मुवषेषवमुङजीयान ॥ पमतुाः
कमटउथाः ङजीयानापहुउमुवेषषेषवमुम वाग२ वा
मुडिः षनिव षमलो षदेउ षहृत्रि उमेउअ उमेदि
०२ वनषषभाः कमटउथाः
डिमुवियं डिमुक्ययशी ॥ पज्ञेषपज्ञमामुडीयाज्ञा ॥
कमटउथाः
वाङ्मषुवा वामङषुवा भूहयपज्ञमेनिहमा उमङमा निम
०२
यः ॥ वनषषमेहूः मकवः मुवयववपवम्ककवंनवा ॥
कमटउयहूः
पहूःपवःमकवः मुवानिषुककवभाप्रेडि नवाविकल्पेन
क. वाकुवः वाक्कवः षम्रुभाः षम्रुभाः ॥ ०४ केङेलडे ॥
को. ३ ०४ पवङपडकेलमटवेवनेष ॥ उकवःपमत्राषमुपवेषु

पररूपमाप्नोति प्रत्येयेषु षमः इत्युक्तम् ॥ संसे ॥ य
स्तु सुकारः मकारे सह माप्नोति इत्युक्तम् ॥ शुंदंगीयः ॥
येषवत्रियेर उल्लपति ॥ डेहसवजकारः प्रचमडजवं ॥
पञ्चडेहवनषुषसेहः परेदकारः प्रचवत्रमडजंवाप्नोति,
वाग्घीरः वाग्हीरः षल्लः षल्लः ॥ षट्तुरुत्य
ण ॥ षट्त्वलुटैवरूतपणमंल्लुः श्रुत ॥ एल्ना
हृद्वेपणः श्रुरेह्निः ॥ पञ्चाहृह्वेपणएल्नाः श्रुरेपरेह्नि
भवति उत्कृर ष्यवाज्ञुद पसत्रिद ॥ नेत्रस्तुकयेः सक
रसवश्रावप्रचसम् ॥ पञ्चेरिकारस्तुकयेः परयेरश्राव
प्रवंसकारमाप्नोति ससाद्वश्रावः परवयनाभवाद्रवर्णेय
रिल्लाष्टेड भवांस्त्रिरेति भवांस्कृष्यति ॥ एवाभसक
रेश्वाभकारम् ॥ नेत्रसश्रुपरेश्वाभकारमाप्नोति भवाल्लय
ति भवाल्लपति भवाल्लरवं भवाल्लेत ॥ ए०येः षका
रम् ॥ नेत्रः पवश्रावप्रवं षकारमाप्नोति ए०येः भवांष्ठी
कते भवांष्लुरुरः ॥ हठल्पवसुल्कारम् ॥ नेत्रःल
कारमाप्नोति हठल्पुपरेश्व सदल्लीरः सदल्लीकते सद
ल्लकारः ॥ हमयेः सकारम् ॥ नेत्रसुमपरेत्रश्रावप्रवं
सकारमाप्नोति भवांसुनेति भवांस्कृहति ॥ लेलम् ॥
नेत्रः लकारे, त्रश्रावप्रवं लकारमाप्नोति भवांल्लिखति ॥

सिद्धंवा ॥ नेतुःमकारेऽनुस्वारपदान्ते कद्धंस्वानुरः स्वानु
रः पदेऽपरगादमकारेऽनुकारमितिमृत्युभ्य मदस्वा
नुरः ॥ भेदस्थानं हल्ले ॥ मकारः पदान्तेनुस्वारभावमेति
हल्ले हं दसामि ॥ भेदस्य स्थाने पूर्ति ॥ मकारस्य करणे
रस्थानेऽनुवर्तितपूर्ति यंभूतं पूर्तिकिभ्य मतूङ ॥ वर्णेवर्णातुः ॥
परस्थानभूवर्णेपूर्तिवर्णातुःभूत मानुः मक्तितः ॥ वर्णे
तद्भूतयंसमंवा ॥ मकारः पदान्ते वर्णे परे तत्भूवर्णभूयत्वं
वाप्रोति पञ्चमस्थानः हक्कारेषि हंकारेधीत्याहि ॥ ओष्ठ्यहल्ले
नमत्रिः ॥ ऊमकारस्य मकारे ॥ मकारस्य मकारोष्ठस्य विसर्ग
उत्वं प्राप्नोति उचारणं मकारलोपः दत्रूः ॥ मूपरोलोपेर
स्वरे यं वा ॥ मकारादूर्ध्वे विसर्गलोपः भूत यत्वं प्राप्नोति स्वरक
रणेस्वरे ॥ नविसर्गलीयलोपे परः सन्धिः ॥ विसर्गलीय
भूलोपेऽन्ते परः सन्धिकदंसमूत दरमुग्द दरयाद ॥
यस्तल्लिपिरस्मिपरेषि ॥ रेफस्य विसर्गविडिते विसर्गस्यसिप
रेपिभव रत्वं प्राप्नोति धिपवति सुरेस भुतरद भुतनतः ॥
कापयेलिक्षुप्रलीयंनवा ॥ विसर्गलीयः कापयेलिक्षु
प्रलीयंवा प्राप्नोति कः करोति कःकरोति कः पचति कःपचति ॥
ष्यधर्वत्वं ॥ मकारस्य ष्यधर्वते मकारे विसर्गउत्वं प्राप्नोति सि
वेदङ सिवेंठका ॥ विसर्गलीयस्वकेवामभ ॥ विसर्ग

क
को. १

श्रीयसूक्तमपरेसकारभाष्येति भगस्वयेवासङ्घः कस्वरति क
स्कृदयति ॥ ऐङ्वायभा ॥ विमलश्रीयः ऐङ्मपरेयङ्भा
ष्येति कस्त्रीकते कस्तुरुरः ॥ उखिवाससभा ॥ विमलश्रीयस्थेव
मपरेसहभाष्येति कस्तुरुमिवः कस्कृडति ॥ पठयेमपक्ष
श्रीयंरवा ॥ विमलश्रीयः पठयेः परयेमपक्षश्रीयंवाष्येति,
।मिवयीति मिवः पाति कढेलति कः ढलति रेढेतडे ॥
रेरलेयंश्वरस्वश्चवेसीङः ॥ रेढेरढपरलेयभाष्येति रेढ
श्रुवः श्वरस्नसीङः श्रुङ श्वस्तारस्तभा ॥ मयेमेयावायरङय
भा ॥ विमलश्रीयः मयेममपरेयरङयंवाष्येति कस्वेडे कः
मडे कथस्युः कः थस्युः कस्मापः कः मापः मंयुक्तस्वङ्घरेस्त
रु कः स्वेडडे नयेयेयपरेस्वेस्त विमलश्रीयस्तनेयेवा कस्क
वरः कः स्कवरः ॥ पथमपरलेथ्टेस्कृते ॥ पथममङ्क
ह्रंपरेविमलश्रीयेस्कृतेपरलेथ्ठेवति पथमस्तुः मङ्डति ॥
स्तुठेस्हमवमवश्वर ॥ स्वकरठेमङ्कह्रंपरेविमलश्रीयेले
स्तुः स्तुङर यङ्कंभाष्येति श्वर ङवास्तुङ्कः ङवायाङ्कः ठेपङि
ठेयङि ॥ येथवतिलेयभा ॥ उखास्कडेविमलश्रीयेयेथ
वतिपरलेयभाष्येति ङवाताङः ठेङङि ॥ येथवस्वरपरः ॥ नामिपरेरभा
नामिनः परेविमलेयेथवतिश्वरेमपरेरतभाष्येति स्वग्रिरङ
स्वग्रिङ्कः स्वग्रीयकति ॥ स्वरह्रयविश्लेषस्तुमकारंकयव

ण्यैः ॥ षष्ठ्याद्यैर्विभक्तः कपवर्णैः मकरमाप्नोति
षकरान्तकमि कंभकम्ब षाद्कमा कल्कैर्ब्रवैधृते षषष्कारः
षयष्कभः षयष्कंभः षयष्कम्बः षुयम्दश्भा षयष्क्रमः
षपष्कलः षाद्कयपरुष्कुत्रिडिवाष्टभा उपपयःकभः स्र
करपदविम्दषृते कष्कः सन्त्रैर्वेतिकिमा षपैप्नः षयैति
मुः षराष्टपषृकिमा स्रः कभः ॥ ङिविभक्तभत्रिंश्चमाषु ॥
हृक्रियाकवैणक्तः ॥ यः मवः क्रियावाची भणाद्वंक्षुः सृष्टा॥
हृणाद्वविकक्रिवलभकुवल्लिक्सभा ॥ णाद्वविकक्रिवक्रिडभ
ऊवष्कक्रऊपंल्लिक्समंक्षुसृष्टा ॥ उभक्षुवाविकक्रयः ॥ मिक्र
लभा षभाक्रिमभा एहंक्रिभा लेहंक्रिभा लभिक्राभक्रभा
लभिभाभा लिक्रभ्रुपा लिडविकक्रिमंक्षुभुम्भल्लिक्सद्रवः
सृः मिक्रलभा ङिपृवभा षभोमभा ङिक्रिद्रीया एहं
क्रिभा ङिक्रिद्रीया लेहंक्रभा ङिमडुत्री लभिक्राभाक्रभा ङि
पक्रुभी लभा वभा ष्रुभा ङिवक्षी लिवभा ष्रुपा ङिमपु
भी मिरपृविकरः लमपरपाक्ष्णरवक्तः स्रमहृल्पृवभैं
वाष्ठुभी ॥ रैवभैविभक्तीयः ॥ रैवभकारपैविभक्तः
सृष्टा विरामविक्रमाको दरः क्रवृंदरो । लभि । षकरसौ
क्रभाप्नोति परल्लैपः दरः ॥ षकरेल्लैपभा ॥ षकरैविक
क्रकरेल्लैपभाप्नोति दरभा दरो ॥ मभिमभृमनः ॥ षक

श्राः पिः

कु॰
को॰
५

रेस्रीद्रमाप्रेडिसमिसमहुमस्तरः भृज्ञ दराग ॥ ङनए ॥
मकराद्रः एप्रहयः ङनाद्रिमं भृप्रेडि ॥ रघवक्रेहें मर
ह्रः भ्रवदयवकवननपवनाभुरेपि ॥ रेळमकरणवक्रेहः भरे
पळ्डेनकरः भ्रवदकरयकरवकरकवननपवनेहूवजिडेपि
करभापहूडे दरे ॥ मकरेस्रीद्रंप्येपवडि ॥ प्येपवळ
प्रेविडक्रेमकरेस्रीद्रमाप्रेडि दराहूभा ॥ डिमेश्रा ॥ मक
वम्रवेडिभा विभाबाभृाञ ॥ मरकदेविकदाभिः ॥ मरभृ
कदेकञ्हे मुळिवक्रेविकरीभृाळिडि भृपे मरेकवळः भवभृ
वडूं दवेः पळ्ळिकद्भृ्भे मदरभम कहूंकलेहिः मडयाम
द्रेवाण्डि मदृपेवद्रहेडेडिवकृभाभकरः ॥ तेदः ॥
मकरम्द्रवेभ्रहयमकरः भृाञ दराय दराहूभा ॥ पुळिव
द्रहें ॥ वद्रहेउद्रवेपुळिमकरःमकरः भृञ दरेहः ॥
दमिवाञ ॥ मकरम्द्रवेमिभ्रहयभृञ भृञ दराञ दराहूभे
दरेहः ॥ दभृ ॥ मकरम्द्रवेमभ्रहयः भृभृाञ दरभृ ॥
भ्रमिम ॥ मकराहूंभृप्रेडि भ्रमि नमया दरपेः ॥ द्रीया
द्रेतुमराळिः ॥ उमवद्ध्रवगभमभुडीयाद्रेविडक्रेमरडःमरभृ
क्रिःभृाञ ॥ भ्रुमिमरः ॥ दश्वनमीमह्र्हःमरभृामेवराग
मःभृाञ ॥ मीद्रमामिमेरो ॥ दवेमीद्रमाप्रेडिमराबामि
हूं दराभ्रभा दवे दरपेः मह्रुद्रडे ॥ नामिकरमरःभ्रहय

विकल्पागमः सिध्यंत्वविमलनीयधातुरेषि ॥ नामिनः
ककारादेस्तस्य पदः सूत्रयन्ति विकल्पागमस्तु नामिन
विमलनीयान्यकारेण सूत्रवादिरेपि सकारः पद्मभाषेति द
थ ॥ पुमादिरपि सिः संबुद्धिः ॥ पुत्रान्ते सिखल्यः सम्बुद्धि
संज्ञः स्यात् ॥ ह्रस्वनदीसम्बुद्धः सिर्लोपश्च ॥ विहः पदस्य
सम्बुद्धेः सिर्लोपभाषेति देवर एवं शिवकल्पद्रुमः ॥ एतस्म
वर्तंभा ॥ पकारान्तस्य नाम्नः पदः सर्वनामां रंडंभूषेति स
वविश्व उठउठय दउर दउभ पउपउउर ठउर ठउ ह विभष
सभिस प्रवपगावरङ्गिलिनुगापगणगालिसूववस्त्रायाससंज्ञ
याभा सुभङ्गुडिणाप्तायाभा पद्मरंवदिदेर्गीपंसहानयेः
हल उल यल लउल उलभा पलभा लक द्वियुष्मल पमल
ठवतु किम सवनाभावि सर्व ॥ सेसवनाम्नः ॥ पुत्रनु
स्वनाम्नः परेरेः सेस्युउ सवसे ॥ लभिस्मउ ॥ सव
स्मउ ॥ भगभिसवउः ॥ पवलन्तुस्वनाम्नः परस्यामः
सगयामः स्युउ पद्मसहेसवेषाम ॥ लिःसिन ॥ पउः
सवनाम्नः सवस्मिन सर्वादवउ सर्वविश्वाद्येभूकगतुः
उठसक्षिविहद्विमगामः उठे १ उठहभा ३ उठयेः ३ उभू
दर्पाणिकदाभव सूत्रयगादलोउरतुगादलसिडि दउर
दउभ सूत्रयगादलेनउरउगाहेतु ससःसवपदाय ठलूपदा

कं.
को.
१

येनसमानाधिकरणपकत। ॥ प्रवादिज्ञ ॥ सम्मदरैए
भ्रावेहँशाधेति प्रचेवाप्रवाः हवभ्रायांकिम। समिश्रवा
मकः प्रवीश्रतद्गः समंस्लयांकिस। तत्ताजरवः स्वेशा
त्रस्नर सस्मीयावा श्वाह्लत्येभवा सतवेसतरावाणदवा
हतहगः सतवेसतरावा मात्कैः परिणतीयाऽतह्गः ॥
विकल्पतप्रवादेः ॥ सम्मास लमिहः सकत। स्मिनेवाकहे
त प्रवस्मत। प्रवात। प्रवस्मिन। प्रवे स्वंपरासीनामधुनां
ल्लयस। सेधंसववत। ॥ सल्दस्मिवा ॥ एतसा येहवाधेति
सल्लेवासल्दः द्रितयेवा द्वितयाः सेधंदरवत। सल्दधप
सरवसतय सत्कतिपयनेस सल्दादिः हिडीयानुरात। सै
सकत। स्मिनेवेधत द्वितीयसै द्वितीयाय सवंसतीयः ॥ द्वन्द्व
भ्यास्व ॥ द्वन्द्वसमासम्भ्यादतः भवनाश्रेएभ्रावेहंरधेति
कतर कतमेवा कतरकतमाः ॥ नञ्समबनाभिकम। ॥ द्वन्द्व
समासम्भासैवनाश्रवेहरदितसवनाभिकंकदन प्रवाप्रवा
य ॥ द्वीयासमासे ॥ सस्मिन्कतिउषा मासप्रवाय वा
हृपिन मासेन प्रवाय ॥ वन्धादिन ॥ प्रवेकम। स्मियस
वाय नो स्त्रियं कपसत्तनप्रमृति तत्राहसन्मग्वः तिल्लवः ॥ ए
रात्रस्मवेवा ॥ एतसमचन एतस्याश्राह्मवेसकस्मसचिसत
सकहवत। तिल्लवौ तिल्लवः पञ्चहल्लगविसदववत। ॥

[illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥
[illegible] ॥
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥
[illegible]
[illegible] विश्वपाः विश्वपौ विश्वपाः [illegible] विश्वपौ ॥
क: [illegible] ॥ [illegible] वि
कौ: [illegible]
७ श्वपः विश्वपा [illegible]

किम् ददः परलेपेन ज्ञ स्वस्मि ध्वनः पंसि उलि ज्ञुन्तुले
न्हुमिहकेदना मेधं विश्वपावज् दविः ॥ उद्वप्त्रिः ॥
उकारान्तुउकारान्तुशब्द मस्थि त्रिभक्तिः शुङ् ॥ स्यकारः प्रथमा ॥
पत्रेः परस्यपृष्ठयः प्रथवल्मापहृते दवी ॥ उदेहेणे
मि ॥ पत्रेः ङः पृङ् ङः पञ्चमीमि ददयः ॥ पत्रेरभेक
रः ॥ पत्रेः परशृभिकरेलेपमाथ्रेति दविभ ॥ मभेकारः
ममरेसप्त्रियाभ ॥ पत्रेः परशृमभेकरः प्रथवल्माथ्रेति
ममन्नमशृरः पञ्चियाभ दवीन ॥ एरा ॥ पत्रेः परशु
पृष्ठयेराशृङ् पञ्चियाभ दविश्रु दविह्लाभ उ दविठिः ॥
हेम ॥ पत्रेः ङः पृङ् ङः पृङ् शृङ् ए पृष्ठये ददये दविहः ॥
एमिएभेरलेपप्त्र ॥ पत्रेः ङः पृङ् ङः पृङ् रमिएमेः उये
स्वकारशृलेपः दवेः १ ददेः १ दवीश्रुभा ॥ एरेमध्रवः ॥
पत्रेत्तिपृष्ठयः प्रवेल्पवल्मेरमजास्यकारः शृङ् दवे दवि
म ॥ मभ्रुह्वम ॥ पत्रेः ङः पृङ् ङः पृङ् ज्जुङ्प्रवगाहमि
लेपः ददवे ॥ माहुप्त्र ॥ मपिमध्यशृन्तुः पत्राशृङ्माप
मभ्रुह्लु ॥ प्युएमामभ्रुह्लु ॥ रान्तुशृपणयाप्तीडः शृङ् ॥
हल्पाप्त्र ॥ मिल्लेपमाथ्रेति लिल्लुन्तुरकारशृ मापा ॥ प्य
एहु ॥ माहुरन्तुरेशृङ् प्युति मापाये १ मापाघः मापा
यभ मापीन ॥ रमपिप्तुप्रवत्रिः ॥ मपिमध्यप्तुपिभृह

ये त्रिसंख्येन यत्नम्। आत्मा आत्मानौ आत्मानः। आत्मा आत्म
नः॥ एभिरेभिरहमः॥ आत्मपञ्चमहं एभिरेभिरकार
उदंश्शब्देति आत्मा: ३ आत्मे: ३ आत्मानम्॥ आत्मपर्देहि:॥
क्रमस्यात्। आत्मे आत्मसु देवाय॥ पठितव्यमाने॥ त्रिसं
ख्येन एतेन समासेन त्रिसंख्यः पन्था पन्थे पन्थाः ३ पन्थे सर्वं द
विवृत् समासेतुनस्यपदस्य॥ कर्तृब्रह्मणी संज्ञका॥ धकार
नकारान्ताया: संज्ञाया: कर्तृसमासब्रह्मपदयोलक्षणसंज्ञकाश्च
त्॥ नित्यपरस्य पदस्य। लकारसमासे लोपपदस्य पस्य
पदस्य कटं ध्यायंत्रप्रत्ययः कर्ता ३ सर्वं द विवृत्॥ पदस्य
नामविशेषे॥ पदस्य गं ढ्रुनाम करः प्रत्ययः विशेषे॥ अथ
कर्तृ प्रत्यये॥ अवप्रकदेकस्य हृदयेवलोविकारवाभिप्रत्य
प्र ३ दृहम् ३ दृये: ३ इयः शीला द्विहि: द्विहः ३॥ इत्यु
क्त॥ द्विमक्षस्य प्रत्ययेन गागमः प्रत्ययः द्विमक्षप्रमइयाप्र
मः इयाप्रम। द्विषु॥ पथिमथ्यृभुक्षीणामात्॥ पुंसोऽसुङ्
। पन्थाः॥ पन्थाः पुमान्॥ पुमांसः पुमान् प्रत्ययः पुमान् पन्था
नौ पन्थानः पन्थानम्। पन्थानौ॥ पथ्यृभुक्षीलोपम्॥ पथिमथि
ऋभुक्षीणां अत्र लोपमात्रेति पथ्युपेन्द्रे॥ इतोऽत्सर्वनामस्थाने॥
पथांनकरोल्लोपमात्रेति पथ्युपेन्द्रेहस्त्रेत्म पथः पथा
पथिभ्याम्। एवं मथि ऋभुक्षि मस्के वाऽनडुहि: वाऽनडुहौ वाऽनडुहः॥
वाऽनडुहि: भ्याः केपिकीयमेवाऽनडुहकः। एवंवाऽनडुहीनद्विनद्विवाऽनडुहीनयम्।

क. को. ३

१६।

ॐ नमः कृत्यृहयाहृतं ब्रुव नमोहभमः मम: खकर: प्रवभाषेऽति

मकरसूनकरजाम। ॥ वाउथ्मीम। वाउरमीन। वाउथ्मूत्वाउथ

मीहूम।३ वाउथ्मीछिः वाउथ्मूं वाउथ्मीहूः३ वाउथ्मूहः३वाउ

थूहिः३ वाउथ्मूत्वाम। वाउथ्मी वाउथ्मीथ्रदेवाउथ्मीः नवंययी

यभृहिक्रयः ॥ ॐक्रहृहितमनी ॥ ॐक्रत्रीभूतवाभकेनमोअंहूतः॥

ॐकवात्तुह्नि: ॥ नमोअंहूमीकवात्तुह्निह्लियभाषेऽति प्रियाहू

यहिययहूमप्रियहूयमी ॥ ययहूंसंवाहिनिर्लेपमम। ॥ नहूःपर्ये

स्वयेसंकिह्लियभाषेऽति प्रियहूयसीम। थूंसिममथूत: उगित

क्रम। प्रियहूयमीन। ॥ नहूतिकुभामाम। ॥ नमोअंहूदहूरे

धांलवतंखूखामांयधाभूतं तिक्रुम। कृम।कृम। नतेहू: प्रियहूय

मूहूं प्रियहूयमूः३ प्रियहूयमीनाम। प्रियहूयसूम। ॥ यधू

हूकूमूः ॥ नमोअंहूकहू देप्रियहूयमि संधंवाउथमीयउ।

नवंवहमिययमीलहू छिहूः नेहूर्यनेहूहू यहिलहूः संधं

प्रियहूयमीवउ भूतीः ॥ ॐक्रतेहिथ्रवेश्वरे ॥ णतेरीक्रहूः हू

रेथरेउथ्र्वीधः उहिधूतहू ॥ वरेकहूवयेमूहूसंयेनाहूवो ॥

योरेंक्रत्रीणहूहूअंयेनाउहेवोनहवउभ्रूउयेनरेकभ्रवयेदवोभूः

भूवे भूहूः भूहूः भूहूं भूहीरहः भूहू भूहू रहः भूहि संधंवाउथ

मीवउ। पहूयकरकेउवध्रवयेहूहू मूहूणियो वामलीः ॥

तियेरितमाम। ॥ नीमहूक्रवेरिथ्रहयकुमा। भूउ। भामहूमा। संधं

नमोउह्नि उमोलहू हूनीसीलहूहूउ: महूनांउउयेहूसांनि निपेकदमन

ष्णुडम् नाविसिध्याद्वत्ति सिद्धम् । नवरूपाण्डं देवादः नद्युः ॥
नद्याभीनाम ॥ नृगरूपाद्वदि नद्यदौ नद्यदः नद्युतमा न
द्युता । नद्यु देवद्युः नुभानद्युम नद्युम द्युधा नद्युउ उदैवम
दैउा पैउा नुमनद्या सिद्धनुम नाद्यपः नद्युः पिउापिउौ पि
उदः पिउरं पिद्युा सिर्धणाद्यवउा नवएभाइद्यपः नानरौ
नरः नरभा द्युा द्या उद्धमा ॥ उवा ॥ उमवैमीउंवाप्र
त्रि राभि उपाभ्राम उपाभ्राम नविरैः उष्व देवः ॥ रैः ॥ रायू
हलुनमि पुद्धं रूपाउा रः रायौ रायः राहूभा रायु देवः ॥
गोरौत्युटि ॥ गोसवर्णरूपत्युटिकरूपाउा गौः गावौ गावः ॥
पुष्पमिरः ॥ गोसवर्णरूपाभा गावौ गाः गवा गोहूभा ॥ गोद्व ॥
तभि नमिवलिपः रूपाउा गौः उ ग्लौः ग्लावौ ग्लावः ॥ उक्तिभ्रवा
गुः पंलिङ्गः ॥ किंउमवृ ॥ उकवानुः मद्यवर्णद्धः मृद्धु
मंलुः रूपाउा ॥ मृदुयामिउ्रौपभा ॥ शौप्रैरि उभा ॥ क्वी
भा ॥ मृदुयाः पवारुपूरयः वैद्वभाप्रैरि उभौ उभाः ॥ वे
मेरा ॥ मृदुयापद्धं रूपाउा एउमेः उभया उभाहूभा उभा
भिः ॥ एवत्रियैयारूपारूपाभा ॥ मृदुयाः पवाम्निएकवम
किद्याविपमनाति यैयाभा याभा याभा नउह्नः उभायै उभा
हः उ उभायाः उ उभयोः उ उभानाभा उभायाभा उभाभ्य ॥
मभ्वद्वेम ॥ मृदुयापदं देउमे ॥ मवनाभ्रगुमनवेद्धव

164

प्रवाः ॥ मद्भुसंल्लकस्रवनाप्रः परिमांरवडंवमनानांप्रा
गमपृडः स्त्रप्रवाप्त यैयाम। याम। यामः सुः सवसृस
वस्तः उ मवामाम। मव सृाम। मेषंउमावउ। नवंविस्रुम
यप्रकरागुः ॥ द्विगीयाद्वगीयस्त्रांवा ॥ पुहुरवउंमम
विस्त्रप्रवाप्तयैयाम। याम। यामिवासुः द्विगीयसृ द्विगीय
यै ॥ त्रिमांवा ॥ त्रिप्रगिगांमक्षांवस्त्रीत्रिममामेत्रि
उद्भवनाप्रः पनसृपस्यसृमवनामकंवासृउ। उउनप्रवा
यसृः माउउनप्रवाउसृ उउनप्रवसृ उउनप्रवायै मभ्रा ॥
स्त्रिश्राजनाम। ॥ मभ्रुस्तु देवभ्र मेषभमावउ। मवं पकाय
पवे उमावउ।
त्रा पल्लामकः एमा एरमो एरे एरमः एगाउस्ति विमयाः
विम। विमः भ्रनमावल्भूरंदजीय उतिमसृएः विभूम। वि
त्रिः सर्ष्यषिपृसमउतिमसृमः विसृपउः पउ पस्तृमिहत्रि
मीपाः विम्रुपावउ। मतिः मती ॥ स्त्रप्रस्त्ररवति ॥ उपुर्वः भ्र
रंभृास्तवीद्रजी पृमिसंल्लु स्त्रप्रस्त्ररवतिवमवनिपमीवस्तृउ।
मद्दै मद्दः उमदम। पञ्चेहल्लामिमदविवउ। ॥ डिमदुर्वि
यांतिमदस्मविठजे ॥ भिपायंवपुमामर्यैरनर्यैरउजेसविठ
जे ॥ उपसंप्रवे ॥ प्राभ्रुउः पमयिवस्तुस्त्रामपवफः डिमः उ
क. डिमत्रिः डिमल्हः मोल्हे ॥ नामिमहीद्रम। ॥ पतिमहीद्र
को. प्राप्तुउः नामिडिमस्राम। डिममृदमस्त्रस्रुल्हे ॥ भिपामाल्हप। ।
७०

श्रियां वा तु भानाङ्कगत्वान्यथाभूतेर्द्विश्च ज्ञातुमभ्युवर्णः गौ
री गौर्यौ गौर्यः देवीति एवं नदीरूपाः लक्ष्मीः देवी एवं
तरी तन्त्रीरूपाः श्रीः श्रियौ श्रियः श्रियैः श्रियै श्रियाः ३ श्रि
यः ३ श्रियैः ३ ॥ भ्रूणापि श्रियं वा वाभि ॥ उवर्णः स्त्रीभू
ताख्यावीदूते प्रश्रिवानमीसंख्याभुः श्रीणाम् श्रियाम् श्रि
यि श्रियाम् देवीः श्री ॥ श्रीव ॥ श्रीमतःसूत्रङया भ्रुवे
श्रियौ श्रियः ॥ वाम्भ्रूमः ॥ श्रीमतःसूत्रङयावाम्भ्रूमः श्रिय
म् श्रीभ्याम् श्रियः श्रीः श्रिया श्रीभ्यां श्रीभिः ॥ श्रीनदीवत् ॥
विकल्पापवादः श्रियै श्रियाः ३ सुगमविधौ इत्यनवहुरा
गमः श्रीणाम् श्रियाम् श्रीषु देवीषु एवमदितवत् श्रियं प्र
तिरूपगत् स्त्रीसमतःसूत्र स्त्रीषु ठवेलत् ॥ नमस्त्रुकस्य
अपिनातुहरं ॥ नमस्त्रिहः पञ्चात् वाद ३ वमात्पदत्वात्
स्त्रीहुः अपिमतःत्वात्त्वहस्व श्रियामीश्वरयः स्वात् येहः
श्रियामीश्वरयमहसूत्र तेनमतयः स्त्रीश्री गौरीवत् स्त्रः ॥
हूमतःसूत्रउवाभ्रुवे हुवौ हुवः श्रीवत् भ्रुव
हुःजातुवत् ॥ हूमतःसूत्रउवाभ्रुवे हुवौ हुवः श्रीवत् भ्रुव
भूः पुंवत् स्वभा स्वभावौ स्वभावः स्वभावम् स्वभूः स्वभू
स्वभूवाम् देवम् भावापिद्धवत् । सभि भावः रा ग्रंथ
त् हूमतःगवविभूत हीः हुवौ हुवः हूमा हुः नौः ग्रौव
त् ॥ उक्तिश्वगत्याः श्रीलिङ्गः ॥ ॥ सुगमतमस्त्रवतुः स्त्र

गाढतृढः ॥ तडश्ववत्तुनामः यदृड्ढाद्वरः स्यात् ॥
एकराद्मस्पृष्टिमवृ ॥ एकवत्तुत्वं नपुंसकलिङ्गद्वयेः
र्मेर्लोपः स्यात् तसूमसयनामः त्रुनम् ॥ दीर्घम् ॥ नपुं
सकाद्वाक्यस्वरयोर्हृस्वोऽति द्रुवे ॥ एत्युर्मेः सिः ॥ नपुं
सकस्मनयोः सिः स्यात् ॥ एत्युर्मोनपुंसके ॥ षट्ंभेलोस्पृ
तम् ॥ पठुराद्गुणेः ॥ पठवस्पृष्टातुस्पृत्वं नपुंसकस्पृष्ट
णेत्रनामः स्यात् तपकादीडः द्रुमादिवत्तृतम् सि
लोपः दिदुन मेधंवत् एवंतनुणवनादयः हृदयेस
कौषु भांसानां हृद् तद् पुसना भांसा पुतेसः हृदि
हृदः हृदूम् तदनि तद्रा तदूम् पुमानि पुम्रा पुमहृ
म् मांसि भांसा भांतूम् इति ॥ यतादेस्तुः ॥ यस्म
दयोः स्पृभेलोपः यस्पृमत्तुनामः यत्त् यस्पृत् तत्
कत्रत् कतमत् सेधं द्रुनवत् ॥ सुवेदत्वेनपुंसके ॥ नपुं
सके सीद्भूतस्पृद्रुत्वः स्यात् सीपं द्रुनवत् ॥ नपुंसकस्पृमे
लोपेनमतदत्तम् ॥ मधुंसकद्वयोः स्पृमेलोपः स्यात् तयोः
परयोर्दत्तं तत्र स्यात् इति निमित्तवत् ॥ विरामविकारादि
शत्वं नपुंसकस्पृमेलोपेपि ॥ विरामविकारादिपदत्वं तत्र नपुं
क. सकस्पृमेलोपेनतेपि स्यात् तलोपः भवति भवती भवन्त्य
का. नीति भवन्ति भवत् भवतुस्लोपेनतेनस्पृतृस्पृष्टीवस्पृ
११

मध्वतृपुरुङकदंवेधुडे यङ्गमीत्रिना यथांउतृतुवेनाउवृशउिङ्कुग
ग हेभ्रपधिवारि ॥ नामितःश्वेरे ॥ नपुंसकमूत्रधंभकपृश्नरेवग
नामःशृाउ वारिणी वारीणि भरवधृवभा हेवारि हेवारे वारिणा
वारिण वारिणः उवारिणिः वारीणाम वारिणि सेधंदविवउ ॥
दधिउधंभ्रुधंवङ ॥ दधिउः भ्रमाङ्गेउङ्गामृडुंयंभकंएतेभ्र
देवाधंवउ शृाउ श्रुतिने श्रुतये ॥ यक्तिमतिभङ्गृकूभाउङ्गु
ति ॥ यथाभङ्गेनशृाउएतेभ्रूरे रेङ्गाणाःमत्रीयः मत्रा मत्रे म
त्रःमत्रेः रेहेवा मत्रि मतनि सेधंवारिवउ यवणभृम्मयः
मणि मणिनी मणीनि हेमणि हेमणे एतेधंवङ्गाभणिया मणि
नेहाति मधु मधुनी मधूनि हेमधो हेमधु यवंएभृमयः मल
मलनी मलूनि हेमले हेमल भूत्वा मलनेहरति णायणायली
णायलि हेणाउः हेणाय णायग्र णाइहति यवंङ्गयकमृमयः
भकृमनाग्रहमूात्रिमउङ्गे भूरि भूरिणी भूरीणि भूरिग्र भू
रिहृभ भूरीग्रभ बहु बहुनी बहूनि बहुना भत्र भत्री भत्रि
भत्रहरति ॥ उदितुनपुंसकलिङ्गः ॥ वाविराभ ॥
मृवभाचेवङ्गभानानां पृए भूधिभवाशृाउ भक्तिमजीयः भिद्युलिक
भिद्युलिना भिद्युलिनि भिद्युलिनाः भिद्युलिनम पृएंमजीयः
भिद्युलिनृभ भृधिधेभ्रमभः भिद्युलिङ्ग ॥ मवनमणानमीनां
म ॥ मवजाउभृमानमीनांमाभृमृनाङ्गंशृाउ विराभविङ्गानि

ध्यास् । ध्यासा । पठित्वा । प्रच्छ्य । भूत्वा । क्रिमा । उक्षित्वा । विदेद्गा
प्यः पयोभक । पयोभगा । पयोभ्याम् पयोभमः पयोभ्यूभ । पयो
भक्ष । गत्वेश्वावंमत्ये वत्रेवजातुः ॥ संयोगान्तस्य लोपः ॥ विश
भविष्यादि भ्राल । भ्राल्ली भ्राल्लः भ्राल्लभ । भ्राल्लि ॥ हल्ङ्यादेर
पक्षः ॥ मनोमृत्युक्रान्तुर्वोकर्त्रेपक्ष संल्ले: म्रात्व ॥ पत्रपक्ष्म
कृत्त्रेः ॥ पत्रपक्ष्मलोपभाप्रेदि पथ्यध्निश्चेत्पुक्लेमनतुकृत्त्रेः ॥
पत्रेवलोपः प्रवभृम्यसीद्धः ॥ पत्रेदिरकरमृल्लेपेठवडि प्रवमृ
मक्तभ्रमृग्सीद्धः पथ्यध्निश्चगादि भृाम: भृामा भृाक्ष्भ । भृडल
भृड्क्ष्वि भृडीमः भृड्क्ष्भ । उमल उमक्षि ॥ उमक्ष्मीमः ॥ उम
ज्ञ । मकभृ उमीमादिमेठवडि पथ्यङ्गादि उमीमः उमीमाकु
क्ष्भ ॥ मदसंडिरसांआएभिश्रि डिरयः ॥ विधामेडेयथाक्ष्सं
भृः क्विवत्तुक्ष्डे मभृल मभृक्षि मभीमः मभ्रक्ष्भ । मभृल मभृ
क्षि मभीमः मभृक्ष्भ । जिदल जिदक्षि ॥ जिद्दिरग्नः ॥ जिद
ज्ञ । मकभृ जिरग्नादिमः पथ्यङ्गादि जिरग्नः जिदक्ष्भ । भुलज
भृाक्ष्डः रलोपेरभृड भृाल भृाक्षि भ्राक्ष्भ ॥ विश्वगेवयेज्ञाकृ
श्वगादिवमृक्ष्डेक्षौ ॥ क्विवत्तुक्ष्डेभवगाश्रविश्वगेवयेज्ञाकृश्व
गादिरवयवभृपद्विश्वदिमः भृाउ पमभृल उरुयभृल विश्व
भृल दिवभृल ॥ युक्लेरभमासेनक्ष्रुए ॥ युक्लत्तुरागामः भृाउ ।
नडभभासे पत्रभ्रावनान्तेसंयोगान्तलोपः युल युक्षि युक्षः

[illegible] ॥
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] । [illegible] । [illegible] । [illegible] । [illegible] । [illegible] ।
[illegible] ककुब्भ्याम् । ककुब्भिः ककुब्भ्यः ककुप्सु ।
मरुद्भ्याम् । मरुद्भिः मरुद्भ्यः मरुत्सु । [illegible] । [illegible]
[illegible] । [illegible] । [illegible] । [illegible] । [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] । [illegible] । [illegible] । [illegible]
[illegible] । ॥ [illegible] ॥ [illegible] महत् ।
[illegible]
[illegible] महान् । महान्तौ
महान्तः महतः महता महत्सु । हे महन् । ॥ [illegible]
[illegible] ॥ [illegible]
धीमान् । धीमन्तौ धीमन्तः धीमतः धीमता धीमत्सु । हे धीमन् ।
[illegible] । [illegible] । [illegible] ॥ [illegible]
[illegible] ॥ [illegible] । [illegible]
[illegible] । [illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ।॥

[illegible] ॥ [illegible] ॥ [illegible]
[illegible] लोपः [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible] द्विपात् द्विपादौ द्विपादः ॥
पादः पत् [illegible] ॥ [illegible]
[illegible] द्विपदः द्विपदा द्विपाद्भ्याम् ॥ [illegible]
[illegible] ॥ [illegible] लोपः ॥ [illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥
त्वमहं सौ सविभक्तेः ॥ सविभक्तिकयोर्युष्मदस्मदोः [illegible]
त्वम् अहम् [illegible] ॥ युवावौ द्विवाचिनि ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥
यूयं वयं जसि ॥ सविभक्त्योर्जसि यूयं वयमौ स्तः यूयम्
वयम् ॥ [illegible] ॥ [illegible]
कं [illegible] ॥ [illegible] लोपः ॥ [illegible]
को [illegible] लोपः [illegible]
०३

युवाम् आवाम् ॥ शसो नः ॥ युष्मदस्मद्भ्यां परस्य युष्मान् अ
स्मान् पुंल्लिङ्गे ॥ टाङ्योरिति ॥ त्वामहं युष्मदस्मदो
रन्तादेशौ विभक्तिवचने त्वया मया ॥ युवावौ द्विवचने ॥ युष्म
दस्मदोर्द्विवचने प्रत्ययादौ युवावौ विभक्तिवचने युवावौ स्तः यु
वाभ्याम् आवाभ्याम् युष्माभिः अस्माभिः ॥ तुभ्यमह्यं ङयि ॥ ङ
विभक्तौ युष्मदस्मदोः सह तुभ्यं मह्यमादेशौ स्तः तुभ्यम् मह्यम् ॥
भ्यसोऽभ्यम् ॥ युष्मदस्मद्भ्यां परस्य भ्यसोऽभ्यम् स्यात् युष्मभ्यम् अस्मभ्यम् ॥ प
ञ्चम्या द्विवचने ॥ युष्मदस्मद्भ्यां परस्य ङसेः पञ्चम्या त्वत् मत् यु
ष्मत् अस्मत् ॥ तवममङसि ॥ सविभक्त्योः युष्मदस्मदोर्ङसि परे
तव मम युवयोः आवयोः पुंल्लिङ्गे स्त्रीलिङ्गे नपुंसके ॥ साम आकम् ॥
युष्मदस्मद्भ्यां परस्य साम आकमादेशः स्यात् युष्माकम् अस्माकम् त्वयि
मयि युष्मासु अस्मासु ॥ त्वामौ द्वितीयायाम् ॥ युष्मदस्मदो
रेकत्वे द्वितीयायामेकवचने त्वा मा आदेशौ वा स्तः ॥ वांनौ द्वि
त्वे ॥ षष्ठीचतुर्थीद्वितीयासु द्विवचने युष्मदस्मदोः पदात्परयोः
वांनौ आदेशौ वा स्तः ॥ युष्मदस्मदोः पदात्परयोः षष्ठीचतुर्थीद्वि
तीयासु बहुवचने ॥ वस्नसौ ॥ पदात्परयोः युष्मदस्मदोः षष्ठ्यादिषु बहुवचना
न्तयोर्वस्नसौ आदेशौ स्तः ॥ तेमे ॥ पदात्परयोर्युष्मदस्मदोः षष्ठीच
तुर्थ्योरेकवचने ते मे आदेशौ वा स्तः ॥ धर्मो रक्षतु वां पातु वो
ऽपि ते नो मे ॥ ईशो वां नौ वो नः ते मे ॥ पाठे शीघ्रं त्वा मा श्रु
त्वा च त्वा मां त्वा मा ॥ यथादेशः ॥ पादादौ वर्तमानयोः

रोतुदिमानभूः, जीवपक्षिभ्राक्तं सुंविनिद्रुतभीश्वरः सतुकुल
हवीकेशभंगंभक्तिप्रियालय, एवमर्दसभूह्भम् ॥ अस्मिन्नेव ग
म ॥ सर्वादिदासर्वनाम्नोऽदिगिभर्तितथा, दारिभ्रुसभांसवक्रति ॥
दसत्वजत्वभूणोऽभूजीयादिकाम्ब्यसत्वजहमहत्त्वज् ॥ दकरा
तभूसत्वजात्वभूमदजीयादिकाडेगदेश्चत्वजतं भूज् विसर्जनहस्व
रादि उपान्त्यवल्लोपसम् । क्लुकुञ् क्लुग्गौ क्लुकुभ्यम् । वि
क्रुञ् विक्रुणौ विक्रुभ्यम् । रा रायौ रायः रायं रायौ ॥
सल्लोपः ॥ अथ नम्रेतिक्तः गल्कः गल्कु गल्लभ्यम् । गल्लचिवि
हसि, पदस्यान्ते भूत्वल्पवतुभ्यामिति सिभ्रम् । ततविन, गल्लि गल्ल
ति ॥ रसभृह्नौ ॥ लिङ्गत्रयकरभूल्लेपः देगल्लन् । सर्वभल्ल,
यल्ल यल्लौ यल्लः प्रथमसंयोगादिस्लोपेन यल्लः यल्ल
भ्याम् एवा ॥ एवत्रवत्त्विभभावनाक्तः ॥ एवत्रवृतः एवतिंत्र
दिसभाप्रति, नाक्तयैरेसोत् रतुसो एवतो एवतः एवतः एव
तः एवत्भ्याम् । देएवत् एवाकः किम् । एतवा यल्लदत् । पञ्च ३
पञ्चभिः पञ्चभ्यः ३ ॥ संख्यायाः ष्णान्तायाः ॥ षकारनकारान्ता
याः संख्यायाः जसशसोर्लुक् स्यात् ॥ नान्तस्योपधायाः ॥
नाम्युपधादीर्घः लिङ्गत्रयकारलोपः पञ्चानाम् पञ्चसु एवं
सप्तन् नवन् दशन् ॥ अष्टन्शब्दस्य ॥ अष्टनस्तुआ भूत्
क॰ भवतामविकल्पेन वैकल्पिकं सेनभाव्यमत्वसदशमध्ये स्यात् ॥
कौ॰ जुतसप्तभ्यसः ॥ जतकराद्भुतैरयैरैन्नं भूत् ॥ कतिप्रभ
१८

परिभवो ॥ विकारिस्त्रिभुः नभवर पश्वेउ पश्वाकिः पश्व
हः पश्वानाम। पश्वाम पुरुहवे पश्वपक्षवउ। ॥ उदक्रुमाद
भूंसीसोम ॥ पिमाभपणयालीत्रः सो पनभृदुंसोम कइद
ल्हं कइदत्रि कइदलः ॥ दजेदिक्रिमपणालीयं ॥ पञ्चि
मतिदजेदसृख्यः भाउ। कइख्यः कइख्या कइदहभ। कइख्रिउ
इदलि देकइदा। मवंदक्रिा यमश्रिा पुदभा। प्रभा। ॥
सोमभख्यवद्रख्यवा ॥ भख्यवक्रुद्भः भख्यवत्रादिभंवश्रेति,
सोमेदभाविति निकमउभ। भख्यदा। भख्यवत्रा भख्यवत्रः
भख्यवतः भख्यवहम। पक्षिभख्यवा ख्यतियाणवउ। ॥ स्रयवभ
येतांम ॥ पवांवपृउद्रभख्यएिम्रवे भखेतः भखेता भखवहभ।
भख्यवश्र देभख्यवा। मवंस्रा। स्रवा। उदमुप। उदमुपो उद
मुपः उदमुहम। विणय। विणहे विणहः विणहम। विणश्च ॥
उदमियभयंश्रेसि ॥ उदमउयंस्राद्रंसिक्षयंसोपयम। हद
5 मिइ ॥ मेस्रेदः ॥ क्रिमदृयदिक्रांहमालीनांमसृमः स्राउ। उमो
उमे उमं उमो उभाम। ॥ एमेवः ॥ पाकउदमस्राउर्मः पव
येः पवादिमः भाउ। पांव ॥ पक्रूक्रोस्कः ॥ पक्रहयवजिा
मृउदमेकावस्राउ। विकक्रिहह्लो कमिक्षवपवोभवो लीढः उ
हभ। ॥ उभ्रक्विभिः ॥ उभ्रावकउदमः पवमृगिसोकिवदे
सः पेस्राएः पहम। पकिः हव्यक्रिइजउ श्रेउवि पर्श्रे पश्चउ।
पमृपवयेः पधाम। पुक्रिा। पश्च पनभ। पणे पमा। पवेन पव
ये: आकमुउभकेनेहक्रिमववउ। ॥ किंकः ॥ किमक्रुसृक्रि

ठक्कौकः कैकैमववड्॥ भैनोश्डैः॥ णोश्रहृमृभमृत्तः मृणोक्रौ
भूमानां॥ भ्रवेणतुरनाउ॥ यमृक्वैभमृनङ्घभञ्जमभ्रवेणतुः मृ
ड्णतुम्रुङ्गपंभ्पृव्रिहङः प्रङ्घुनिवडुउ भूमाभो भूमाभः भूमाङ्घ
भ्पवंशुआ मङ्घरः॥ मडुरेवामव्रश्रेङ्घभ॥ नमृणिश्रुव
हृङ्गवेम मडुरः मडुह्निः मडुहूः ३॥ मडुरः॥ पुभेशगगामः
लहूभ मडुल्रूभ रेढभैविहृश्वडिवडुउ ङेनयकवेभहुङ्गयूट
येवेढमृभपिमनविभनः मडुहु प्रियमङ्घुः प्रियमङ्घुनो प्रि
यमहूरः प्रियमडुरः प्रियमडुहूभ॥ मधुङ्गुवृङ्गयेङ्घभूः॥
मडुवरङ्गुदैः दप्रियमङ्घुः॥ रूभौ॥ प्रिवासमवृमृङ्डङ्गुवाणः
महैः भृक्विवो भमिवः॥ वाभृा॥ प्रिवप्रडुवामृादमि महूं
भविवभ॥ प्रिवडहूक्लैः॥ भहूहूभ भहूप मदगामिहू
नवभ उामदकाउामदमौ उामदगूभ पठउमदका पठउमदमौ पठ
उमदगूभ दमोश्दिः भविणे भविमौ भविमः भविहूभ नमै
वेङिशुाउगञमेवागङ्घभ नकानणे नमौ नमः नहूं नहूभ द
मभणे दैमभृमौ दैमभृमः दैमभहूभ मणका मणमौ मण
मः मणगूभ मणे ३ मङ्गिः मङ्गुः ३ दहू॥ मदैल्लैन॥
जडङभूपमैनैल्लङ्घुमृाउ मल्लुभ मङ्घु गीरणे गीरङ्गौ गीरङ्गः
गीरहूभ प्रपउणे॥ उमरेगीङ्गुरे॥ णोउदेडगउोमेउयैः
यंगङ्गौमुःविगभङ्घहूकाङि मिलैयेङुउविभनः॥ गमिप
येगभ॥ गमिनः पवैविभलगीयैरभापृति भृावविभनः भपीः
भपिमौ भपीङ्गभ पवंभङ्गुः भाङुङिलीङ्गः विङ्गा मनैरव

कु:
कौ:
०५

स्वरः विद्वांसौ विद्वांसः ॥ पञ्चस्वर्गादिष्वेकवचनेषु विद्वच्छब्दस्य
...द्वम् ॥ पुंसि वस्वन्तस्य यि परे विदुषः विदुषा ॥ विद्वद्
...वसि ...ज्ञि ... ॥ ...देवमेव
...विद्वद्भ्याम् विद्वद्भिः विद्वत्सु देवि
...सेदिवान् सेदिवांसौ सेदिवांसः सेदुषः सेदिवद्भ्याम्
...एवं ...ईयिवान् ॥ ... ॥ उखा उखास्रत्
उखास्रतौ उखास्रतः उखास्रद्भ्याम् एवं पर्णध्वत् पुमान्
पुमांसौ ३ पुमांसः पुमांसम् ॥ पुंसो ... लोपः ॥ ...
पुंसः पुंसा ...लोपः पुंभ्यां पुंसु ... ॥ उशनस्
...नो ... ॥ ... ॥ ...
... ॥ ... ॥ ...
उशना उशनसौ उशनोभ्याम् । ...
...उशनः ... ॥ ... वेधाः वेधसौ वेधो-
भ्याम् ... एवं चन्द्रमाः सुमनाः । ...
... । पिण्डग्रः पिण्डग्रौ पिण्डग्रोभ्याम् एवं ... दोः दोषौ
दोषः दोष्णः ... ॥ ... ॥ ...
...ः ... ॥ ... ॥ ...
...लोपः ॥ ... ॥ ... ॥ ...
...ः ... ॥ ... ॥ ...
... ॥ ...
...ः ... ॥ ... ॥ ...

[illegible]

[illegible] पथीभ्याम् । [illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥
[illegible] ॥ [illegible]
[illegible]
[illegible] । इदं । [illegible]
[illegible] ॥
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] । [illegible]
[illegible] ॥ [illegible] ॥
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
गीः गिरौ गिरः गीर्भ्यां [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥

०भुक्षः मथिवी
१भुक्षः

सुमनः ॥ सुमनसमिदं चकार ॥ [illegible]

[illegible] सुमनसी सुमनसी सुमनांसि [illegible]

[illegible] ॥

[illegible]

[illegible] । [illegible] ।

[illegible] । [illegible]

[illegible] । [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] तपः तपसी तपांसि [illegible]

[illegible] किं के कानि वाः वारी वारि

वारा वार्भ्याम् [illegible] ३ [illegible]

पयसी पयांसि पयसा पयोभ्याम् एवं श्रेयः [illegible]

[illegible] । [illegible] । [illegible] दोः दोषी दोंषि

दोषा दोर्भ्याम् दोष्षु [illegible] ॥

[illegible] ॥ [illegible] ॥ ॥

[illegible]

[illegible] ॥ [illegible] १ [illegible]

[illegible] ॥ [illegible] ।

[illegible]

[illegible]

कृ० को० ०१

प्रंभ्रुभ\ प्र ङ उ प्रु प्रुः प्रव उउ ङ्गवि उ\ ङति ङ उ\ भद भभ\
भाकभ\ भाथभ\ भइ भलुः श्रुम्रि प्र लभ\ नभः श्वाद भ्रुणा वथल\
वीथल\ स्त्रीथल\ ळिवा ळिवा भायभ\ नङभ\ प्रङ्गु उनभ\ मिश्रभ\ मि
नाय लभ्यु ळिश्यभ\ द्गुङभ\ भीथ्यभ\ नाव्ठभ\ ह्वभ\ प्रतिविलभे\
ङ्गभभ\ प्रुतिभाद्भ\ विशभुभ\ भउङभ\ प्रलाभ्रभ\ प्रुनावउभ\।
प्रुनिभभ\ सिद्दं ङ्गलभ\ प्रुप्रु रंथङ\ नय, उउ, ङ्गा, दि, वं, ना, व, पल्न,
किल वड दद्यु श्रायः भाल\ भाभ्भ नाल\ उाल\ भश्रु, दश्रु, यावङः
यावउ\ उवडा उवउ\ सिउ\ श्रिउ\ यदि मेउ\ नेउ\ नदि नकिभ\
भाकिभ\ भभ्दृति किथ किंतु यद्दउ प्रदद उ ह्मयः पयउ ह्ङ
ठिणायिङ्ग विपाश्रभ्द उ्हृय भंङ्कः ॥ ङ्गभभहृङ्गा उ्हृयभ\ ॥
द्वाभ्रृह्वयः भाङुः भहृङ्गा उ ह्रभ्रृह्वयि, हृयभंङ्कः श्राउ\ नह्वा,
भ्मंभ्मरं भमे कउवे ॥ प्रहृयाश्र ॥ प्रहृयाश्रिदिङ्गनंविह
ङीनंल्नक\ श्राउ, भ, प्रथ, उइ ॥ प्रहृयभवाभ्रः श्रुवाभ्रहृङु
वेकः ॥ प्रहृयानंभवाभ्रंभाहृश्रुवाङुवेवाकुभ्रृह्वयः श्राउ\ ।
प्रहृङुङ्गभ्रिङल्नेभउ धाह्रभ्राक भ्भयः भंङ्कयाभपिविश्वङि
भीहृयियंभृकीङिङः । कभृिभभहृङः उह्वकेः ङ्गभ्रिउभ्भवः भव
कः प्रल्नः भभकः । ह्भ्र प्रभ प्रथकः । प्रयकभ्रिङेठवा\ ठ
वकभ\ । भंङ्कयाभ्रिङिउङ्गे ङलिङ्गकभ्रृह्वयाङभ\ भंङ्कयाभ\
भङकः ॥ उतिभ्रीठहु मेव नवविधभिङयां कङङु के भहृं प
हृयभदिङ नियङ्गिङ्गिनिभभाभ्रानीङि कहृभ भुकभ्भक पां कलीपकेथ ॥ ॥

ॐ श्रीगणेशाय नमः ॥ ॐ नत्वा शिवपदं वन्दे गुरुं श्रीविष्णु
विष्णुं श्रीचक्रपाणिं सिद्धिदं प्रणम्य शुभाशुभं फलं सकलं वक्ष्ये
वसुभागं फलं भवति ॥ वसुभागा मधुनी पञ्चमी हस्तनी पञ्चमी पौ
र्णमासी शुक्री शुक्लपक्षे द्वितीयाद्यष्टमी तिथिरुत्तमफलदायकः ॥
मध्यमः भावफलकम् ॥ यत्र मध्यमवासो भवति अष्टमवसु
भागः भावफलं सकलं भवति ॥ शुभः फलः ॥ यत्र कथ्यते
म ॥ वसुभागा तिथि मासे पक्षे मिथुने शिवमासे मघा श्रवणा
धनिष्ठा शतभिषा पूर्वभाद्रपदा ॥ इत्यादि वसुभागा सकलं भवति सर्व
सुखसम्पत्तिप्रदम् ॥ शुभपक्षे पञ्चमी तिथिः ॥ सकलकार्य
म् वसुभागादीनां विचारं कृत्वा सर्वकार्यं चतुर्दशी पक्षे
पञ्चमी सकलं निवृत्ति ॥ यत्र शुक्रवारे ॥ वसुभागादीनां पञ्चा
ङ्गवशात् चतुर्दश्यां सकलं निवृत्तिः शुभमस्तु ॥ शुक्लपक्ष
पञ्चमी कर्मणि ॥ अथ सिद्धियोगः उच्यते शुक्लपक्षे पञ्चमी सिद्धिः ॥
कृष्णपक्षे प्रतिपदादि तिथिः ॥ कृष्णपक्षे द्वितीयादि तिथि कर्तव्य
शुक्लपक्षे सप्तमी श्रवणे पुष्ये मघा पूर्वायाः ॥ उत्तरा रोहिणी
यमः ॥ उत्तरा रोहिणी मघा पुष्यं मृगशिरा हस्तं चित्रा कर्तव्य
यं सप्तमी पूर्वाह्णे प्रथमे ॥ मेषादि राशि शुभपक्षे पञ्चमी ॥
उत्तरायणे शुक्लपक्षे पञ्चमी सप्तमी ॥ शीलि शीलि पुष्य
भरणी भाद्रः ॥ द्वितीयः पञ्चमी शीलि शीलि वसन्ततिथि भाद्रपद
भरणी सकलं निवृत्तिः सर्वा सकलं पिण्डं प्राप्य वाग्मिति हि ॥

शुभस्य कृष्णपक्षे पञ्चमी
चतुर्दशी शुक्लपक्षे
चतुर्दशी पञ्चमी कर्तव्य
मि ॥

कृ॰
कौ॰
१३

पकारः ॥ नाम्नि भूयसामान्येऽपि मध्यमः ॥ [illegible]
[illegible] भूयसामान्येऽपि [illegible] मध्यमः [illegible] ॥
[illegible] ॥ [illegible] ॥
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥
[illegible] ॥ [illegible]
[illegible] भवति ॥ [illegible] ॥ [illegible]
[illegible] भवतः ॥ [illegible] ॥ [illegible]
[illegible] भवति ॥ युष्म
दि मध्यमः ॥ युष्मदि भूयसामान्ये भूयसामान्येऽपि [illegible] ॥
[illegible] भवसि भवथः भवथ ॥ अस्मद्युत्तमः ॥ [illegible]
प्रथमः शेषे ॥ [illegible] ॥ भवामि भवावः भवामः ॥ स भव
ति तौ भवतः ते भवन्ति त्वं भवसि युवां भवथः यूयं भवथ अहं भवामि
आवां भवावः वयं भवामः ॥ युष्मदस्मदोः पदात्परयोः [illegible] ॥ [illegible]
[illegible] ॥
[illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible] ॥

[illegible]

[illegible]

पयः पयसा पयसे पयसः पयसि ॥ पयसी पयसोः ॥ पयांसि पयोभिः पयोभ्यः पयसाम् पयःसु ॥

कं
कें
०७

फुः मिः षुडम ॥ नाभिकर्करवृल्हेः पर्रः षट्यविकराया

मपुः मकरः षड्भाप्रिति ठविषृति ठविषृति ठविषृडः ठविषृति

ठविषृमि ठविषृषः ठविषृष ठविषृमि ठविषृवः ठवि

षृभः ॥ हंदीनिक्रियाडिपडिः मृडमृडभमृनमृः मृडम

मृडमृभमृवमृाम मृडमृडंमृडंमृषाः मृषामभमृडंमृमृाव

दिमृाभदि ॥ मृमंदिडनिहदीनिक्रियाडिपडिः मृाडपृठ

विषृडपठविषृडभपठविषृनपठविषृः पठविषृडमा

पठविषृडपठविषृभपठविषृावपठविषृाभ ॥ पठवि

षु ॥ पठड ॥ पुडपुषुडिष ॥ पडः परयेरनयेषामा

विकरः मृाड पठेडु पठेडु पठभपठ षेपठश्रेपठेपठावदे

पठभदेपठडपठयाडभपठेरपठेषाः पठयाषाभाप

ठडभापठेयपठेवदिपठेभदिपठडाभ ॥ पुंदडाभाषा

भावेः ॥ पडः परमृाडभाषाभेरादेविकृः मृाड पठ

डभपठडभपठभृपठेषाभपठभृभपठेपठवदेपठ

भदे ॥ प्रमेडरेमवद्रिः ॥ पुनठवरू पथिहयेमसष

सुमदडरेम मनृम रेतिमडरिडवद्रि मल्लठवत्रि ॥

पुरदीनवद्रिरादेः ॥ पुरदीनठुराभादिवद्रिः मृाड

दषुरहडीतियाडिपडिषु पमपवादः पठडपठडभपठ

डपठषाः पठषाभपठडभपठपठवदिपठामदि सि

मडठावठभ ॥ डवंजमृषठवनाहवनः ॥ षकरठवना

हूं पद्ममुद्रवज्रमुद्रे वज्रः स्वाहा । तिथिषु तिथिधारामा ॥ सुरुं वै स्तान
कराय ॥ यकारादयस्वाहा त्रिकरमूलं पः स्वाहा सुद्धं पदे ति ति
घर तिथिषुः तिथिधाराम ॥ मितिणकरे ॥ लेपः स्वाहा तिथिषुं
तिथिघि तिथिपुथि तिथिपुथि ॥ नामा निनुहमरे टमूः ॥ यणुरु
ग्राम्ष्ट्रानिनुहमान्टमूरु रहमुरुपुम स्वाहा देवियामा ॥ पुमः न
न्टरपुयपुरु ॥ पुमरुमूहान न्युरुयरपुयपुरु ॥ मुरविति स्व
नद्विचमानिमिरुदुरुद्रिवमरे ॥ द्रिवमानिमिरुस्व ययः स्वर विति:
स्वाहु: मद्रिवमनेदरु पञ्चाम्हवगीद निद्रिहम ॥ वकारवरूमू ॥
पुहामभूयवरूपुरस्वाकारः स्वाहा ॥ कवनमूसवनः ॥ पह्ण
भमसुत्रिः स्वाहा रत्नं णंमकु णंमहरु णंमकिरे ॥ नस
हूंबमुहूभमवुणवुपरमायामू ॥ उक स्वाहा पद्ममदनिपि
स्वाहा पद्मं णंमहध णंमहध ॥ नाम्रुन्मुरुनामीरहुरुगीपव
म्मामूणंठः ॥ नाम्रुनामुरुः पनामामूयणकरमुमूटः स्वाहा णंम
नद्र णंमकु णंमनवदे णंमनमद ॥ यमुवेमपरमं ॥
पुमरुमूपुम कुणयुमुरुयपुरुरु पुद्गपदन्कुरवेपरमं पुरुम ॥
पद्गमनमूणीरुद्रनमवमसूम ॥ पनाणीरुद्रलरूम ॥ पसूनः
मवह ॥ पहामभूणीकारमूमीद्रः स्वाहा मवहमधरेमयां पदले
पः णमाम णमाममरु: णमामः णमामिघ णमाम
घः णमाम णमाम णमामिव णमामिम णंवकुव ति
तिरा तितिरा तितिराव: तितिराभी तितिराभाव तितिरापु तितिरादे
तितिराभूदे तितिराममदे तितिमीपु तितिमीयामाम तितिमीवर ति

+ नवुकरमूंवममानमीद्रूंपदलेपिमहुरु णमाम णमाममुरितिरुनिमिहुतीरि किंयणामहेल उमुरु पुराय पुमणिर
हहमाकरवहमूतिमकुयणुरे भवरुद्रितिमहुरुमीद्रंयमामूर उमदवाणमके मरुह द्रिवुपमीदे
वरेकवागमयवामूतीरियणामम: ॥

Margin notes:
ऋ्वे, भवदुग्धवेमयां पुलिन,
मंपद्मनकुमूमनिपुदहम
नमूणनागीद्रूयरलनयप्रतिदयव
द्रिवमनमूकार । मरलायदय
नुजानकरलनरमरोक्रुणाकालजुणदनकरलेषुय योतिरिवदुःसिहुदुन्दिनुदरलमामसुणसुरि ...
मंमूवनहरुरियहुपहुनीकामू मरुदुम ... द्रिवमनेमूस्वाहा
नवदं मिरुद्रनमवमसूमिदिवमनदे ... स्वाहानिमरुक ... [illegible]
नमहरुरिसुद्रनमदलामनर पामनिसुरुनिरुसमदु लिपद्रलंपः । ग्रप्रुम ।
मनुसूवामनुप्रयांमपररु: ।

थीभ्युः पथिवीयाम्भ्याम् पथिवीभ्याम् पथिवीय पथिवीवदि पथिवीम

दि । पथिभृडे पथिभृडे पथिभृडे पथिभृभ्यः पथिभृभ्यः पथिभृभ्यः पथिभृ

पथिभृवदि पथिभृभदि । पथिभृडु पथिभृडाम् पथिभृनु पथिभृषाः पथि

भृषाम् पथिभृभ्याम् पथिभृ पथिभृवदि पथिभृभदि ॥ स्वदमस्ये ॥

स्वदडे स्वदडे स्वदडाम् प्रस्वदड प्रस्वदथिभ्यु ॥ सिद्धिरिति मात्रयः ॥

...

[illegible]

[illegible]

का०
कौ०
९९

नउसीउद्गुकारादवमादिनकारस्यामः भृतउ। णउँरस्त्रीत्वंयोगः

[illegible]

भृतउ। उवध उवधउः पद्धिउ पभृउ। पद्धिभृउि उद्धिभृउ। उक

ाहउः उमउउमिवभ्रकामिउिणभुदिमउनिविणः भ्रकाउे, उाप

[illegible] [illegible]

गउा उापउि उापिउ। उापउु उापउ। उापीउ। गुणः द्विवहुस्रः ॥

[illegible]

पहाभभूाभवलु ॥ पुहाभभवलुवलुयोरियुवोभुः पभवलु

[illegible]

भ्रव उवीप ऊापउः उवीपिध उापिउा उाप्टउ। उापिभृउि उापि

भृउ। णणगउिम्नालेपालवेध, पलउ पलउ पलउभ।

[illegible]

पुलउ पुलिधु ॥ णकरेम ॥ नउसीउद्गुकारादकारेपरेन

[illegible] [illegible] [illegible]

ामः भृउ। उपलु पुलउ पुलिउाम। पुलिधीषु पुलिभृउ

[illegible]

पुलिभृउ, भूमुगउा, भमउि एधीभकुभमभ्रमगुमग्रमम्रव [illegible] ॥

हिहउतः परभिपणिपञ्चवऊरः पभूमउ। पभूमीउ ॥ पणा

गउिक्तिपन्यैः, पुणाउि ॥ पुणावी ॥ पभावणउकेविषये, पय

[illegible]

करणिवभृउ ॥ उवलुणभ्रिमिउीमीरः ॥ णउावलयिउवलुउा

[illegible]

णकभ्रवाभुउेरभावणउकभृणउ ॥ मिमिपरभद्भवगुनाभ। ॥

[illegible]

वद्धिः भृग। पवीधीउ। पुणीउ। पभूपणउिवद्धिः विवाय ॥ यउव

[illegible] [illegible]

लभूभयगापुवभ्रानकभारभृ ॥ भुरापवगुल विहउः विभृः ॥ [illegible]

[illegible] [illegible]

भूगाुनाभणामिभमपणिमउ्बाउंबालि, भ्रमउंविहभतिस्वातिहु [illegible] ॥

[illegible] ॥

णउभुणंनदि ॥ भ्रवाुनांणउाभपणिमेकरवउंमभ्रमहंविहभ

विएं उघाभणाि मभिभ्रघलियरेउहणवेवाभृउ। भूणा। पुद्धिप

[illegible] [illegible]

णंउन, णधांघलिविहभेवभृउ। उहणः विवयिध विवेघ पुणा

घ विहघः विह विवाय विहिव विहिभे, वेउा पुणाउावीयाउ। वेहे

[illegible]

, पनिभूवाभूमहउम। पुलिव पुलिभ,

[illegible]

ति पुलिभृति पवभृत पुलिभृत, किमयं कयति मिकय ॥ [illegible]

[illegible] ॥ [illegible]

मिकियतः मिकियः मिकयिव मिकिव [illegible] ॥ [illegible]

यियित्रामी [illegible] ॥ [illegible]

[illegible] ॥

[illegible] ॥ [illegible]

म ॥ [illegible]

[illegible]

[illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible] ॥ म

[illegible]

[illegible]

ऊ॰ भावणुके परे, वागोपायीत्
उदन्त्वात् ... मिति वेट्।

यद्वितीये आवणुके विधुते भूधूमूलत्वः अगोपायीत् अगोपीत् अ-
गौप्सीत् अगोपिष्टाम् ॥ ... गोपायाम् ॥
गोपायांचकार गोपायामास गोपायांबभूव जुगोप जुगुपतुः जु-
गोपिथ जुगोप्थ जुगुपथुः जुगुप गोपायिता गोपिता गोप्ता गोपा-
यिष्यति ... गोपायिष्यति गोपिष्यति गोप्स्यति। ...
... पुनरपि ... ।
... ॥ आ-
... ॥ ...
... ॥ ...
... ॥ ... ॥
... ॥ ... ॥ य-
... ॥ ...
... ॥ ...
... ॥ ... ॥
... ॥ ... ॥ ...
... कामयते ... चकमे ...
कामयांचक्रे चकमे कामयिता कमि-
ता कामयिषीष्ट कमिषीष्ट कामयिष्यते कमिष्यते अकामयिष्यत अ-
कमिष्यत। ... ॥ ... ॥ ...

[illegible] ॥

[illegible] ॥

[illegible] ॥

[illegible] । [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] । [illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] पृथिवी [illegible] । [illegible]

[illegible]

[illegible] ॥ [illegible] ॥

[illegible] पृथिवी [illegible] पृथिवीषु पृथिवी [illegible]

पृथिवी [illegible] । [illegible]

[illegible] । [illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] । [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] । [illegible]

णिज्विधानं ॥ कर्तरि भावकर्मणोश्च विकरणो भवति प्रत्यये कर्तृप्रत्ययः ॥

कर्तरि ॥ उपसर्गात् परस्मैपदं णिच्प्रत्ययान्तात् ॥ उकारलोपः

णिचि ॥ णिचेति णिचतः णिचन्ति ॥ उकारलोप

वर्णस्य ॥ प्रथमपुरुषस्य विकरणस्य कर्तरि परस्मैपदं परस्मै

णिचः णिचथः णिचथ णिचमः ॥ मध्यमः ॥ णिचविकरणस्य

गुणे सति णिचयाम ॥ उकारस्य ॥ मध्यमविकरणस्य

णिच णिचवानि णिचवाव णिचवाम ॥ णिचं विधिमायाम

गादिविधिः गादयः ॥ गादिषु ॥ णिचः ॥ दमः

णिचप्रत्ययः ॥ भवतः ॥ णिचलोपः

णिचयाः ॥ णिचलोपः ॥ उपरणायान्तिः

रामः ॥ द्वितीयादित्रयाणां ॥ द्वितीयादि

द्वितीयादित्रयाणां ॥ प्रथमपुरुषः ॥ मध्यमः ॥ णिचः

णिचाम् णिचावः णिचामः ॥ णिचादि ए

गादिषु णिचामि णिचादिषु णिचादिषु गादिषु गादितः

गादिषीषु गादिषीषु गादिषु गादिषु ॥

गादिषु ॥ मन्ति ॥ णिचपरस्मैपदम् ॥ णिचि

णिचं प्रत्ययः ॥ णिचः ॥

णिच ॥ णिचलोपः ॥ णिचलोपः

प्रथमपुरुष मध्यमपुरुष णिचादि णिचादि

णिचादिषु णिचादिषु णिचादिषु गादिषु गादिषीषु

गादिषु गादिषु मध्यमपुरुषः ॥

पचेः कतरि भावकर्मणोः क्तवत्वोः पक्वमिति पक्वाति पक्वः ॥ वचि

करणे ॥ [illegible] पक्ववति पक्ववः प

क्वयाः पक्वं पक्वत्[illegible] ॥ [illegible]

[illegible] पक्वदि पक्वतः पक्ववानि पक्ववाव [illegible]

[illegible] पचे ॥ [illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥ [illegible] ॥

[illegible]

[illegible] ॥ [illegible]

[illegible] ॥

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

कृ. [illegible] ॥ [illegible]

को. [illegible] ॥ [illegible]

[illegible] ॥

प्रकृतित्वं परस्मैपदमिति, प्रथमस्य ॥ तमादिभ्यः आत्मने ॥ [illegible]
परस्मैपदमिति स्मृतम्, प्रथमा ॥ [illegible] ॥
[illegible] ॥
[illegible] परस्मैपदं [illegible]
[illegible] ॥ आत्मनेपद [illegible] ॥ [illegible]
[illegible] उकार [illegible] आत्मनेपद [illegible]
ति ॥ अपर [illegible] आत्मनेपद [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] आत्मनेपदं [illegible]
[illegible] परस्मै
पदं वा [illegible]
[illegible] ॥ [illegible] ॥ [illegible] लकार [illegible]
[illegible]
[illegible]
[illegible] परस्मैपदं वा [illegible]
[illegible]
[illegible] परस्मैपद [illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] आत्मनेपदं [illegible] आत्मनेपद [illegible] । [illegible]
[illegible]

का.
कौ.
३१

[illegible]

148

मेवायाम् । मयति मियते मिङ् [illegible] प्रमिमियते प्रमि
मियते मयितुं [illegible] कवति कवते ॥ [illegible] ॥
[illegible] भावणके [illegible] स्मृतः
[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible]
पः स्मृतः [illegible] ॥ [illegible] ॥ [illegible] स्मृतः [illegible]
[illegible] ॥ [illegible] ॥
[illegible] स्मृतः [illegible] ॥ [illegible]
[illegible] स्मृतः [illegible]
[illegible] ॥ [illegible] स्मृतः [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] स्मृतः [illegible] ॥ [illegible]
[illegible] ॥ [illegible] स्मृतः [illegible] भावणके
[illegible]
[illegible] ॥ [illegible] ॥ [illegible] स्मृतः [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] स्मृतः [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
कृ० को० ३१ करः स्मृतः ॥ [illegible] ॥ [illegible] स्मृतः [illegible]

रुग्णः रुजः ॥ [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] पिबति [illegible]

[illegible] प्रकारान्

[illegible] श्रेयान्

[illegible] पिबति [illegible] प्रकार

[illegible] पिबती [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

पर्वत पर्वतादभ पर्वत: पर्वत्रभ उवाद उवादिष उवत उ
हुउ, वभनिवा, वमति भमृभ डिउ: पवाभीउ पवाभुाभ उवा
म ॥ मामिवमिप्पभीताम ॥ मधांभमृतिमिद्वाद्वभृष: मृाउ
पस्य विकाराणाभमृउ प्रभ: उपउ: उप: उवमिष उवभू वमु
उमृउ वभृउ, वोतउपुमउारे वयउिवयउे पवाभीउ पवामु ॥
नविमृगुलीम ॥ पत्य: परमाक्याभगुल्लमृगुल्लमभमुभारलं
नमृाउ ववोववउ: ॥ वोमिवृयि: ॥ परमाक्यावामृाउ उवाय ॥
दिमृष्वयिवृणिवधृमृमिभमक्षित्वृहमभगुल्ल ॥ भभमुभारलंमृाउ
द्विवभभानमीउ: उपउ: उप: वयिय भृपरमाक्याभगुल्लवावहू
वावं उपउ: उप: वय: मृभमुभकावाउ लिरिहमिल उपयिष उय
उववाउ उयाउ वामीमृ, मृाव भंवरल, मृयउिमृयउे पमाभीउ मृ
राभु ॥ नमृयउे: परमाक्याभ ॥ मृउंमृाउ नभमुभारलंभमुभा
रलं विमृाय विवउ: वृाउमृउं मद्गीउिनिहमिल विमृयिष विमृाय
विमृय विमृउाउं वीयाउ मृभीमृ, कुाभमृगायंमकोम ॥ मला
मवमिामृउिलिपिमिमिट्व: ॥ मह: कउहमृभाल्ल मृाउ मि
मृण: मृलेप: मृहउ लिपिमिमिकुभामृपदिवाउ मृ: मृहउ
मृहूउाभ मृहूमभेतावमरावउीया मृहूभाउाभ ॥ मृहमृ
म ॥ कृयउेहमभृतिहंभमुभारलंमृाउ एुदव एुकुवउ:
एुकविषएुदिवकुउा, एुमभिगाउकुउ:, मृयति मृिणए वाउल
उया मृमिमृियउ ॥ मृयउे: ॥ पमृालिपउकुव: मृाउमृा

पुडः पुवति पपाठ पोठु पुदि पवाति पपोठ पपावीत ।
कुलाकाप्रकाशने ॥ ऊरुडुचा ॥ पभूतद्धिवाशुद्धानोत्तलि
निभाचणकं ऊलेति ऊलेति ऊलतः ऊलवति ऊलते ॥
गुल्हिमुहिंस ॥ ऊलतेगुलिहिंहिमुहिंगुलभूत फालेत
फालेत ॥ ऊलेतेचा ॥ पभूमिमिधरमेधपरु गुल्हिवाभूत
धोलवीत धोलवीत ॥ वेलेः ॥ पभूत्धिधरवागुलः भूत फा
लवीः फालवीः फालविधु ऊलतेमाधिषणेवाभूः ॥ धुवानिद्वि
जीयषु ॥ धवाफेचाऊद्विजीयषुकप्रवशुद्विवसाभूत ॥ न
मनाः मयेगामयेये ॥ नऊद्विवेशुतेमयेगामयद्विते वत
येवमकभूद्विवं ऊलवाव ऊलवतः ऊलविव ऊलवित ।
धुपाधुते । धोति धुतः पधोधीत पधोधु । कुलाशजयांवा
मि ॥ कूवेदुमनाकिः ॥ कूवःपवभूद्धानेनुलिनःभाव
णकभूयद्रमंत्रभूतंवनमभूत कूवीति कूतः कूवति कूते ॥
कूवःपद्रनाभाकिदुधिन्न ॥ कूवःपवेधांवभाणयाधुकिदः
पद्रनांवमनांवदमयः पद्रवाभूः कूवन्नाकिवानेमः पुद
पुदतः पुदः ॥ मेमन्न ॥ मकवेपवेपुदेदभूमः भूत पुदु
पुदपः ॥ हूवेवमिः ॥ पभावणकेविषयेपवाधिहल ॥
पल्विवमिवेदपणयाः ॥ पवेमत पवेमत उवास ऊसे वत
उभूत । उलणोत्रे नति उतः ॥ उलन्न ॥ पभूगुलद्वन
नोयद्वभूत उयावणः यतिउयाउनतुउऊतउदि पयाति

तिङ् तिङ्भ्यः ॥ तिङ्ङे ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible] । [illegible]
[illegible] । [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible]
क. [illegible]
को. [illegible] ॥ [illegible] ॥
३३ [illegible] ॥ [illegible] ॥ [illegible]

[illegible]

भविष्यति
भविष्यतः
भविष्यन्ति
...

परस्मैपदानामेभावकर्मणोः शत्रृ भविष्यति भविष्यतः
भविष्यन्ति भविष्यसि भविष्यथः भविष्यथ ॥ भविष्यामि ॥ भविष्यावः
भविष्यामः शतृ भविष्यन् भविष्यन्ती भविष्यत् भविष्यतो
भविष्यतः भविष्यतां भविष्यन्तु भविष्यतात् भविष्यतु भविष्य
भविष्यत् । स्यतासी लृलुटोः लृट् लुट् भविष्यति स्यतासी
लृट् लुटोः लक्षणे हेतौ क्रियायाः शतृशानचौ लृटः
सदा भविष्यति भविष्यन्ति ॥ लुटः प्रथमस्य डारौरसः ॥ लुटः
शत्रृलृटः शानच् भविष्यमाणः भवितासि भवितास्थः
भवितास्थ भवितास्मि ॥ भवितास्वः भवितास्मः ॥ लुटः प्रथमस्य
शत्रृ भविता भवितारौ भवितारः भविता भविता ॥ यत्र विधिर्भवेत् ॥
लुटि अभिमतकर्मणि शत्रृ भविता भवितारौ । भवितारः
भविता भवितारौ ॥ भवितारः भविता भवितारः ॥ भवितासि
भवितास्थः भवितास्थ भवितास्मि भवितास्वः ॥ भवितास्मः
भवितास्मः भवितास्वः भवितास्मि भविता भवितास्थ भवितास्मि भविता ॥
भवितास्वः भवितास्मः ॥ भवितारौ भविता भवितारः
लिङि आशिषि भवितारौ भवतु भवतात् भवताम् भवन्तु
भवतात् भवत भवतात् भवानि भवाव भवाम लोटो लङ्वत्
भवताद् भवतां भवन्तु भवतात् भवतं भवत भवानि भवाव भवाम
व भवेत् भवेतां भवेयुः भवेः भवेतं भवेत भवेयम्

॥ भवितासि ॥

शत्रृ भविता भवितारौ
भविता भवितारौ भवितारः
भविता भवितारौ भवितारः

क.
के.
३३

सकथि सकथुः सकमति सकथाउ। सकथु देति: सङ्खं सक
ह्नि ॥ सम्ह हेम्भृ हंसंधिस्तु: ॥ ह्नम्भ हंसंधि स्व हये समङ्गडङ्गभ्पउ स्व
सकउ। सोप रवे विभृउ स्वमकउ। स्वमक: स्वमकसीउ। स्वभाम,
कथां सकार सकसिउ, साथ स्वयसिङ्भ्रु साधि ॥ सारवे रिम्र
पणाया स्वल्पृ ह्रनये: ॥ सारवेग्रपण्याःडङ्गस्पादलिस्पृह्राङ्गरो
सापुल्लि सामीडिघ: सिधु: सामति सिधृउ। ॥ सामसारवे: ॥
स्वम्भ ह्नुतिःभृउ। सारवे ह्नसाङेम: साति सामावि सामाव स्र
साउ। स्वसिधुभ। स्वसाउ। स्वसा: स्वसिध पथासीहृत। स्वसिध
उ। सभास सासिउा, सीपीस। सपृिउवरये: सीपीडे पङ्वल
स्पृ सीपाडे सीपृडे ॥ सीपीवीहिविवल्लयकरये: ॥ स्वायीरहु
लेपु:भृउ। उवलेयकरेस सीपीउ सीपीयाउभ। सीपीउभ। ॥
सीपीवीहीङ्ग ॥ गुल्लिनभृउ। पत्नहाभडुभ सीहैं सीपावदें स्व
सीपीउ स्वसीति स्वसीपीवदि स्वसीपिधु, सकभ्रुसिहह्नकमरु
कथ्रवविहुतिलितिग्रह्नकडहभ। सीहुंम्रह्नै सीपिङ्ग सर्वविविले
वेडिगाडुल्ले वमकेंगा वधि अंथडह्न: उमति वधि उधु: उधृउ
वधु उधुउ देति: घडठ: उङ्कि वमाति वमाव स्ववल
ग्रिधुल। ग्रिसन। स्वयल। स्वयमभ। ग्रिस्व स्वयामीउ। स्वयमीउ
उवाम उमडु: उवमिघ वमिउा उधृउ। वमिधृति ॥ उडम
लिप्तकम:३॥ फलबादये: ॥ एदेहादेस्व ॥ स्वम्भदवस्व
विकवल्लभूलकाभृउ ॥ एदेहसीवांभांवलाडके ॥ द्विवस

ंस्मृत। उकारस्मृत्वाद्विरिह इत्स्मितिकत्वेद्वद्विगुणमेसंप्रत्यय
कविशेषविरह ङजभावेत्याह गुणविकरणयोर्वक्तव्यत्वाद्विः ऐदीति
ऐत्त्वः लोपह्रस्वाभ्यां गुणः नलोपः ॥ ऐदीत आत्मनेपदे ॥
ऐदीत्त्वरूपस्य स्मृतः स्यासगुणोप्रसिद्धात्मनेपदे ऐत्ति ऐत्
ति ऐदवानि अचाऐदीत् गुणः अचाऐदयः अदेमीत् ॥ ही
ह्लीकत्वं आत्मनेपदवन्नु ॥ विपत्यनेकार्थाभ्यासस्य अभिं
नु आत्मनेपदं कर्मदभ। ऐऋवांचकार पक्षे ऐदय ऐदवतः
देशः क्रियाते दधृति, चिकीर्षय विठति, ठियेऐदत्त्वस्वरस्य
नामाविगुणे आत्मनेपदे उद्वधृत विठितः विठीतः विठति वि
ठियात् विठीयात् विठिहि विठीहि विठियानि अविठेत् अ
विठयः विठयां चकार विठय, हीलक्ष्यां लिहति लिहीतः
लिहियति लिहयामास लिहय, ... ॥ पति
पिपर्तु ॥ ... आत्मनेपदे उद्वृत्त पिपर्ति ॥ उ
...पणभूत ॥ ...
...पिप्रतुः पिपृतः पिप्रति, पिप्रहतु पिपर्तु अपिपः
अपिपतः अपारीत् पपार, ...
...पप्रतुः ... पपरतुः ...परी
ता परिता, ... ॥ ...
क॰ महाभावे ... आत्मनेपदे विठति विठतः विठति विठत
को॰ ३८ विठयात् विठतु अविठः अविठीत् अविठत विठांचकार ...

[illegible] मिमीते [illegible] लिपः

मिमाते मिमते मिमीत मिमीतां मिमातां मिमीध्वं मिमै [illegible]

[illegible] एदति

[illegible] एदीतः एदति ॥ [illegible]

[illegible]

यक्षावेलम्बाभवन्तः यक्षदिम्बवह ॥

महेश्वरीति गुल्मः भूरङ, तनोरिविहस्थ भूरङः भूमविहस्ते भूग
भाक्ष्यवाफेमैवलवावितिः यहेलङे ष्कवङवाष्कवेयङितालभा
कवः, लनलनने ललात्रि ॥ श्रीलपविभविललनाभो ॥ सवाभाक
वेत्राफेमः भूङ भगुल्मश्रुए लल्वङः गामदनेहूपणलेपः लल्लु
ति ललांमि लल्वङ रंदललनेत्रुमङील लललिये ललनेष्ठु यवा
लल्वयाङ ललभूङ ल्वयाङ लभूङ ॥ ङतिलुदेहमिरकमः ॥
सिवृद्धीकुविलिगीवाभूवदाहूतिभुतिमदमक्षवकत्रिगतिपु ॥
सिवादेहन ॥ भमदृत्विकवलः भूङ कङुविभावणङके मवेव
णः नामिनवेतिङिमीङः मीहृति भूमीहूङ भमीवीङ सिमय
मविङा, नङीगाश्रविमपि, टहति, भामवभावणङकेमिमिहङ
नगिसुसिटगिहमिहपयनुभूः नङिभूति नभूति मिमिङ भगङीङ,
हमीङेदुलने यत्रा हभूति हभङि डङभूल्लथ हुभुहभामिहहम
वा हभङः ङहभङः, लुक्षावयेदनो लीदङि वङहाद्रुल्न भलायङ
भल्वीङ लिगङः ललगङः लविङा लागीङ, मीलक्रय मीयङ ॥
मीनाङिमिनेङिमीलगुल्मवाडुभूङन ॥ सवाभाकवः भूङ गुल्म
कडुभूनहहय भमभु ॥ मीलयङः भूवादवगुल्म ॥ मदभुन
सिमीय मङा, लील त्रेपल्न लीयङ, लीलीएनुल्मवाडुभु
नयपिमाध्रुवभूङ लङलाङ [illegible] लाभूङ, मेङत्रकवल ॥
यहेकवभू ॥ लेपः भूङ भूति भूङः भृत्ति मिमिवाल्नक भूम
क ङ भमाभीङ मायाङ नवकेकेदने लागीभूदहवे ॥ लला
को. नविकवल ॥ भभूयिकवलभूङ ल्वयङ मीपललवितिवम्र ॥
३५

पक्षविहमोभूविद्धुभङतिमिमिवाल्नक नकृभाङगामिहहेल्न लनहव दक्षवङतिवदनेभहङहंमति
वतिरावेमः ॥

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

37 [illegible]

२१९

इन्धे भूल हूं वा भूतउ श्वर गिरति गिलति भुगाग्नीउ ल गाव

लगाल गरिउ गलिउ गरीउ गलीउ श्रक्लीभयाभ भस्तु

यदिह ३७
यक्लुति ॥ श्रक्लीहउ ॥ भ्रमादरभ्रामाचणुकरूलतरभ्रुउ
  इह्लुमीतांश:
स्वंयगादिविहृदिलेपः ॥
भुशक्लीउ यथक्लुइः, मलविमजे, मलोमोदिरिहाकरः भुगा

क्लीउ भुधाधुाभ मभलिव मभृतु, दुभस्लेभस्ले भल्लिति क

    मस्लिनवरिति भ्रमुमरगीउ ॥ भमृत: ३४
गावभः भुगाक्लीउ भभल्लिव भभक्ता भक्ता, भक्तिमेभवे ॥ भ्रमा

दुगणभेनेकरः श्रुगदनिविकरणं ॥ भमादेः श्रुगदेनेकरा
   भुरमि
गाभः भ्रूकृति भक्तुति भुलं भुशभतउ ॥ उदितुमदिभ्रक्रमः ॥
उक्तार्थे मागभवरेतुउइकः   ३९
तिरुणिर भुवरलं ॥ भुगाहूणादेः परनेमकः ॥ रुणमिलं

भूश्वगादेरेनेमकोविकरणः भूउ कउविभावणुक भुलंभुगः
यद्रभेतिरमूणः इहंटजीयः माउणभुहेः ॥
रुलंतु ॥ रुणादिविकरणश्नरुतुलेपः ॥ भुगुलभावणुकश्नु
यदेतुपुरविभः इकाउणिति दकारकरगुअभोगाविभजः उलवरतिदि भुलं गतुलेतुरु मउभु: रुणउरुतुलेपः
उ रुन्द्धः रुन्धति रुन्द्ध रुन्धउ रुन्धीउ रुलन्धु रुन्धुभ भुरुलंउ ज्ञमावः ॥

भुरुलंउ भुरुलः भुरुन्धु भुरुणउ भुरोन्धीउ भुरुन्धु, भिदउी

दीर्घो नमकःश्नुविकरणश्नउ भुशभक्लेपः भूउ उन्धु उन्धि उन्धीउ
   ॥
उनते रिन्धु रिन्धुः रिन्धिमु उन्धुंमरु उन्धिउ उन्धिभुउ, भिन्ध

विभेधलं भिनधि भिंधुः भिंधन्ति भिनधुणिः इः रु: भिन्धि
उवनभूषण उवनेति नभुलः इकाणिति दे दवधरुः गाविणभा
भभिनलं भुभिभधउ भयधिभहृभलन, दिदिदिभिदिंभायामे, ॥
 ३१
तनादेरुविकरणउ ॥ तहूविकरणुदरुउनुगाभः भूउ हृ
 ३२
हनादेगुलिनिभावणुक ॥ नमकःश्नुविकरणउ ॥
 नोः
भुशभक्लेपः भूउ इलंकि इलं: इंकति इलंकि इलंदि

दितः रुपहूं दमूण: उवनयु ॥

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
क. [illegible]
को. [illegible]
३३ [illegible]

करोतेः ककारस्य लोपः स्यात् [illegible] [illegible] [illegible]
[illegible] [illegible] ॥

[illegible] करोतेः [illegible] ॥ संपरिभ्यां [illegible]
करोतेः [illegible] स्यात् [illegible]
[illegible] संस्करोति [illegible] संस्कर्ता [illegible]
[illegible] परिभ्यां [illegible] संस्कृतः संस्कृतः ॥
[illegible] ॥ [illegible] परिभ्यां [illegible] स्यात् [illegible]
[illegible] संस्करिष्यति संस्करिष्यति संस्कृत्य ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible]
विकरणः स्यात् [illegible] [illegible] [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] [illegible] [illegible]
[illegible] [illegible] [illegible]
[illegible] स्यात् [illegible]
[illegible] [illegible] ॥
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] विकरण [illegible] स्यात् [illegible]
[illegible] [illegible] ॥
[illegible] [illegible] ॥
[illegible] ॥ [illegible] ॥ [illegible] विकरण

स्यन्त्स्यते स्यन्त्स्यति, वर्त्स्यते वर्त्स्यति ॥ ३३ अववृतत् ॥ [illegible]
[illegible] विकरणः सुप्तः [illegible] रणे [illegible]
[illegible]
ते ववर्तिषे ववर्तिथ ववृतु ववृत्त वर्तिता [illegible]
[illegible]
[illegible] ववर्तिषु ववर्तीषु ववृत वव्रथ ववर्त्स्य वर्तिसीष्ट व
र्तीषीष्ट वर्तीष्ट । [illegible] सस्राति सृषाः ससृषुः स
सृषिथ ससृषिथ [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] ३२ [illegible]
दीन् [illegible] [illegible] [illegible] ॥ [illegible]
याम् ॥ [illegible] [illegible] [illegible] ॥
उतिहृसिद्धुक्रमः ॥ ७ ॥ ३२ [illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible] ममकरिडमंलुः [illegible] [illegible] [illegible] [illegible]
[illegible] कारिडलेपः द्विव [illegible] [illegible] [illegible]
[illegible]
[illegible] मेस्रत् । [illegible] [illegible] [illegible] [illegible]
[illegible]
[illegible] ॥
[illegible] पीडयति [illegible] [illegible] [illegible] [illegible] पीड [illegible]
[illegible] ॥
[illegible] ॥ [illegible] [illegible] [illegible]
[illegible] । [illegible] [illegible] ॥ ३३ [illegible] ॥
[illegible] [illegible] [illegible]
क. [illegible] ॥
कै. [illegible] । [illegible]
३७ [illegible] । [illegible] ।

ॐ गगनं गगणः सर्वाय स्वाहा। सर्वधर्म ... [illegible]

[illegible]

३३
भप्तकस्तिङ्पदः भवतं श्रयक्ते भवयति भवयते ॥ उपलक्षणे
त्रक्षपवनयरस्यवल्ले ॥ मत्रिमित्राहृमभूयपउपलक्षभूणक
गतुश्रापवनयरस्पृ [illegible] भवल्लेपरमीद्रः पनीभवते । भूभृ
श्रश्रभूलं वभूते पमिभवते । पमभवते । नमाभूणे पभूमा
भते । गाणश्रतिभुल्लिभपे: गाणभानंश्रयुक्त पुल्लगाणते ॥
३४
कैतिङ्मभंत्रल्लिः ॥ भदरम [illegible] सकतिङ्क्षयते: भमभाराल
वाक्षते । पक्षमवते । पमिक्षयते ॥ गहिलनेरथिकरल्लपरे
कये: ॥ पनयेत्रकरगमः श्रुश्रुते नद्विकरल्लपरेकयेः
रक्ष्यति पररक्षते । लक्ष्यति पल्ललक्षते । क्षयति ॥ पत्र
रामीनाम ॥ पतक्षते । पपश्रवते । पमभमते । पपभमते । पम
भमते । पमनमते । पतभवते । भावतक्षणां फलन्नः भवयति
पणीभणते । वश्चिमेधुं वहभभूविमन्दरेपकरेकवाद्य: ।
पववेभुते । पविवेभुते । पमभेभुते । पुमिभेभुते । [illegible]
इतिवकहकूपणफलः पनीकुल्लते । पतकुल्लते । पनीक
ल्लते । पमकुल्लते ॥ श्रापेक्षुल्लिं ॥ श्रपेविश्रुभूमल्लिभंर
भावल्लिभूते पश्रत्रुंपते ॥ मापुश्रफलयेत्ररमिति ॥ [illegible]
३५
क० भहस्रेनिपरेपुपितादेभः श्रुते भायपति कयपति ॥ क्रये
कै० [illegible] ॥ भपरेमध्यरेसकतिङ्भंश्रभावल्लभूते पत्रुद
क० वते भायपति ॥ ल्लेप:पिवतेरीमाहूभभू ॥ पिवतेकथ

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

क॰ [illegible]

को॰ [illegible]

५० [illegible]

उल्लीनामिच्छति ... दिधीषिषति ॥ इविगमिरेभ्यश्चणायाः ॥

इत्येतेभ्यश्च ... पणायामीड्धः ... जिघांसति ... पिपठिषति

...

... ॥ ... ॥

... ॥ ... ॥ ...

... ॥ ...

... ॥ ... ॥ ...

... ॥ ...

... ॥ ...

... ॥ ...

... ॥ ...

विज्ञ ॥ सर्वेः भविश्वरमृक्तुङ मतङ यंहुंम ॥ ङङलेपष्ठ भसू ॥
प्रतिकयेयभाथाफ्पतिअभाघेः भूतिभीमेहरहुयषरूंडइ्हुण
लेपः भूतिदिङि ण्विद्धति तीर्द्धति ऊकूनविधति ऊकूनविधति ऊ
लुङधति यियविधति ययुधति णिलुधयिधति लुलीद्धति भिय
विधति विधाभति प्रमकूयांभवकरूः श्राभुग्रद्धति ऊलंपिपति
धति ॥ भविभीभाफरठलकमकपङपफभिश्रूस्‌ ॥ मयांम
विश्वरमृभ्राचेङभादेमः भ्राङ पहुमलेपञ्च पिर्द्धति फिफतिघि
धति फितविद्मति पिर्द्धति ङ भिद्धङि भिद्धति णिद्धङि विध्वति
लिद्धङि मिकङि पिर्द्धङि मणदिंभयांभसीश्राह्रः पहुमलेपञ्च
प्रृतिविद्धति पतङ पुतिवद्धति तिङविधति । ममतिद्धपणायमीडिप्रुष
ऊवतिदिभविवावाभूः तिङंभति तिङंभति ॥ ङङिभवङरूकमः ॥ २
पृश्रेङती ॥ पश्वभविश्वरभृष्टुपहुमलेपञ्च वंद्धति भमेवकम्रकपृ
भविपुश्रहुमलेपोवावकरूहे मेमङे षणक्रङेवद्धः श्रयमेव पृक
दकभूकिम पश्वमङेतमङः ॥ ॥ ङङिभवङरूकमः ॥ तिणङेरे
कभ्रवद्मवद्धप्रेरीयिङेरियाभमफिदरे ॥ भेरः षस्तेफभजेक
तियाभमफिदरः ऊङवङभावाफिकभ्रवकूकूवादेभङेरमवद्धः य
हुयः श्राद्धमभमीयङभंक्षः मवपदश्रद्ध्रुभिश्रृद्धिघ्रिपृदषुपि
पक्रुङकुहुन्न ॥ पतरूकूटिल्नुनिवेभृङे लेपभफभवञ्चनपम
दफन्नपहुहेकवणदायाभ ॥ पुणञ्चसीपिङ ॥ पनिदवहु
भमृगुलः भ्राभवदफदधपञ्चमृङ ॥ भः भवङिमपरेयकु

बवि वेङ्कुयडे भवेङ्कुयिथु वेङ्कुयांमह्नि भः ४ इमंवाभ्रमयडि

भेभ्रमूडे ॥ यभ्रनहणडेः ॥ हङ्कनाइवमूयभूलेयःभ्रडे

नडुणडेवनिथवे भहङंवा घभ्रभमस भमेभ्रमिथु भेभ्रमांमह्नि

भेभ्रमांभाभ भेभ्रहूडे भेभ्रहूडे ह्निगीयभू ह्निगीनडे ॥ मीडे

ननाभाडेभू ॥ यभ्रानामेडेनभ्राइभ्राहभभूमीङह्नीयिडे

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

वैवक्षः माश्यनुदन्लेन भमाभड्विडयित्रामिलनुडयेगहृडे ठव
डीमिस्कुरस्नाः ठवहृडि ठवडीवामवडि ठवहृडे नवंडहृडि माडु
हृयेहॆ यित्रेभृडे किमिस्कुडि उन्नॆयिस्कुडि नमनः प्रल्ए यंायित्राभृः
नभहृडि वयिवनः पयिमदयाभ वयिवहृडि गुन्मभ मिडुल नु
म्वद मिड्डीयडि ॥ कन्हुम ॥ ३३ नाम्नः कन्दल्ः पुमिस्कुयंाननहभा
नायंाकन्हुरयम्बम्हुग पडकहृडि ॥ ३३ उपमानानि माने ॥
उपमानान्कुमल्नुमानेजैवायिनृडं पडमिवामवडि पडीयडि मि
हृभ पणिकनम्रदिव्रनहः पदकीयडि भक्तु ॥ ३३ कंयुनायिःम
लेपम्ब ॥ उपमानाकुयंमानेजेवाप्रयिस्कुडं माडुहृमलेपम्ब
वा ॥ ३४ प्रुहृडाम्ब ॥ प्रुम्नेपदंहृडं लभुडवामवडि लभुयडे
नसयडे ॥ ३५ ठयिडयंकुंयंवदयो ॥ ठयिडयंकुंयद्रिमेयलं
श्रीलिहं डदयिरहये यंवकुडं डन्श्रयडेकहु ॥ यदुमेय
मडिमीडः डनमिवामवडि डसमडि नसवडि मडहृडाक्कुम्ब
मकदम्ददेजनुयिवकहः कभ्रायहनडे कभ्रायडे यायंकयुम
म्हडेडहम ः रेभक्रुडयेहंकमहंान्हमेल्वडुभानायंामनल्मडे
रेभक्रुंवडयडि रेभक्रुयडे डयमः पवमेयदेम डयम्बवडि डयहृ
डि ॥ वाधेयहृकेरेहडक्षुमरेवाध्वमस्रुभडि वाध्वयडे डयमयडे
केनयडे मदवेरकलदहकयुमयहः करेहज मदकरेडि
मदयडे डहडि । भक्तिनमुक्तिनीदरेहम्ब । भक्तिनयडे मु
क्तिनयडे भानयक्तिहेवेमनायंा वेमयिडरेवमेक्षायामीनि सावं
वेमयडे भानायडे नवंमः यममरजकुमदः ॥ ३७ नामिहम्लि
मनुादयेनहः ॥ नभकुाडहन्नानुदेवयायेनदेजेयः भुजं
दमीयहुवाभृभ ॥ डलेम्बवमेनिरंमलेयेवाभुः डस्यडे

क॰
को॰
८८

पक्षणायते पयायते पयसूते स्त्रवत्सूत्रं गाहूते नाहूते ठवहूते डहू
ते । लिङ्कृदुगमारेऽ विधूदयीपीढते ॥ वेट्रेयेयफऽस्य ॥ केवल
मूककरसूलेयः सूत्रं यङ्गवलेयेद्वाष्टः णत्वद्भुमिदयति पदरी
त्रं दतांमकर पडलेयः दतिस्त दश्यं णवंतक्षभऽस्मदयः ।
उक्तारितंमण्डुऽ ॥ नाम्रेणमूऽश्तिपाहूडस्त्रं ममकवितमंलुः
उक्तरोति डमममुं उदूमवजेकमू॰ः डेकरोति उदूमकरणत्रं ॥
उतिलिङ्कसूत्रेकमरसूत्रहूष्ठवमल्लेयः ॥ पतकस्त्रवसूलिङ्कसूडनि
पतिसूत्रवादरवपवसूलेयःसूत्रं मण्डूकरोति मण्डूयति पदमा
मम्मु पयति लोभातूरमाह्नु पङ्गलोभयति पम्मिका पुरिसूति प
तिदमयति पूडस्त्रलेरे उत्रियेतम उत्स्सूते पयेदूडयति पयेकूडू
उडतः कूमदंबाहूडयति नकुडूउडतः पमाह्नमाम्मुमते मंवमयति
पूडवेमणहूनामिवियते पुपुनामेवऽऽः पदमामम्मु पूडपयति
वेमदपयति मदपयति पामंविपऽति विपामयति कुपेपमूति कुप
यति वीलयाउपनायति उपवील्ययति त्रेकंदमभूति उपत्रेकय
ति ॥ उतिलिङ्कमूडहेतीकिदवृषडूडमायडे मकूलकूपवकूश्रति
पूकुदूप्रपरसूत्रमूदतेवयवसूलेयेनामिनामपूलेठवति कुलमा
मम्मु कुवयति कूयति यवयति कूमयति कूपयति कूठयति । श्रिय
श्रिरण्डिवेऽ रवदलश्रकमकूडूकूदीश्रवतकवरवकाणामिनियेयवा
महूंपूऽऽऽवरवंदिनाणवहूरप कूमिवऽऽमेमः उपहूते पकूऽउ
नामकवसूदीश्रेवऽऽः पुरीतिपानाम श्रियमाम्मु कूपयति कु
पयति कूपयति नवयति तंदयति नायति वहूयति कूपयति कूप
यतिकूपयति ॥ रमवऽडलेयेहूकूनादः ॥ हूकूनादिनापेके
गमूविपरेनमकूमेमः सूत्रं पहूष्नादिसूलेयः सूत्रं मकूपदण
कूत्रवपूमेमः पकूंमऽऽकूमंनेवदमेमाउकूमवम पतिश्ववंकूठं

मैवधस्तत्रानुविवितोभक्षयते। पश्चामामनु शयति भटयति दमयति
दमयति मूलयति परिमूलयति ॥ इति नामधातुप्रक्रमः ॥
कण्ड्वादिभ्यो यक्। कण्डूञ् गात्रविघर्षणे। कण्डूयति कण्डूयते मन्तु
मन्तूयति महीङ् महीयते हृणीङ् हृणीयते मगध परिवेष्टने मगृ
ध्यति कण्ड्वादीनां द्वितीयस्यैकाचो द्वे भवतः। कण्डूयियिषति मग
धियिषति अकण्डूयियत् प्रणमामि यस्मिन्नुक्ते भगवत्कृपा प्रशीयि
षति प्रतिशीयियिषति प्रशीयियिषति प्रशीयिषिषति प्रपप्रशीयिषीत् प्र
प्रतिशीयिषीत् प्रप्रशीयियिषीत् प्रप्रशीयिषिषीत् ॥ इति कण्ड्वादयः ॥
अनुपराभ्यां कृञः। अनुकरोति पराकरोति। अभिप्रत्यतिभ्यः
क्षिपः। प्रतिक्षिपति। प्राद्वहः। प्रवहति। परेर्मृषः। परिमृष्यति
मृष्यति परिवहति। व्याङ्परिभ्यो रमः। विरमति आरमति परिरमति ॥
उपाच्च। उपरमति। अकर्मकात्। उपरमति यज्ञदत्तम्। इति सकर्मकः।
उपरमयतीत्यत्र अकर्मकाच्च। उपरमति उपरमते निवर्तते इत्यर्थः।
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः। बोधयति योधयति नाशयति
जनयति अध्यापयति प्रावयति द्रावयति स्रावयति। निगरणचलनार्थेभ्यश्च। नि
गालयति चलयति। अणावकर्मकाच्चित्तवत्कर्तृकात्। चलयति भ्रंशयति
भ्रंशयते। न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः।
पाययति वासयति वाययति। पाययति यष्टिं पुत्रेण। विषादयति
विवादयति ॥ विभाषा कर्मकात्। कल्पते कल्पयते। मिथ्याकल्पते। मिथ्या
कल्पयते कल्पते कल्पिष्यते। परस्मैपदं इति मन्त्रकृपया दत्तः ॥
इति परस्मैपदप्रक्रमः ॥ ॥ कर्मवत्कर्मणा तुल्यक्रियः। कर्मवत्कर्ता
भवति। हरिहरनवम्। परिहन्नमयतीत्यत्र। गतिबुद्धिभाषणार्थाभ्यां हेतुमते
ण्यन्तानां दृश्यते। दृश्यति दृश्यते। इति दृश्यते। इति [illegible] इति दृश्यते इति

[illegible]

॥ भावकर्मणोः ॥

॥ भवतेर्लृट् ॥

भविता भवितारौ भवितारः भविष्यति भविष्यतः भविष्यन्ति

भविषीष्ट भविषीयास्ताम् भविषीरन्

कं.
कौ.

निमाउभ(कविउलेय: मभृउभेदेदरोल ॥ उमिवा ॥ मा
नवकृताभिनीम्, वेउपणायाहृश्रुवाभृाउ(पमभि पमाभि पवं
पथणि पथ्याणि पवृषि पवृषि ठज्ञौनिमिनलेयेवावामृ:
पठणि पठज्ञि पश्पभनभृलठेनिमि, मिमवानकाग
मेवकृहृ: पलभ्कि पलाठि शृदेभिङ्नभ(शलभ्कि ॥ कम
वङ्कमकश ॥ कदेवकशकमकशभकमवस्मृउ(कमलिया
निकरह्कृनि उनिकमकउदधिमृ: पमृउउकुला: श्रयमे
वठिहृउकधुं पथामि पमन: पठेनिकधुं श्रयमेव श्रवागृहु
उ: कमकउनिवेमवामृ: पकनि पजउकण: श्रयमेव ॥ पद
ज्ञ ॥ पदेनिगो: श्रयमेव पमगुवा मदेनिञिधृउगो: पयेमृ
गुनमण: पमहुगो: श्रयमेव ॥ उउिठवकमपृकम: ॥ ३ ॥
निकल ॥ पणिकरयभ(॥ संपृउिवुउभाना ॥ वउभा
नकलेणउवउभानाभृाउ(ठवउि ॥ मेदाँउीउ ॥ मदमक्रन
येनेभउिणउेनउीउकलेवउभानाभृाउ(णयउि मदनाम: नउम
कउपपदेमदमकृकवेधि पृधुपृउिवमनेगमृभाने पकधी:
कणमेवमउु ननकरेमिठि: नउवानदमिहरु: ॥ पृयेगउ
ज्ञ ॥ मिभृपृयेगाहृउभानामीरांकलविमेम: भृाउ(यावमृ
गनिभाउयेगेठविभृउि वउभाना यावकृङ्कु पराकृङ्कु ठेभृाउ
उहरु: कमकहिमकपृयेगेवा कमकृङ्कु कमठेहाउ पवं
कहिकृङ्कु कहिठेभृाउ कहि ॥ विषाकिधृपक्रुभीम ॥ विणिनिभदृसुमदृसुणी
धृ संस्र शरुनेधृ भपृभीभृाउ(पक्रुभीम विणे पप्रिदेहंणदया
उ(पक्रुभीशृयेगेविणे शृयमेनमदमृउ निभउने उदकृम्भीउठपप

तुङ्गं वा सुमङ्गल्ये सुगन्धं तद्भवान् सुगन्धं तवा वण्डे सक्तु व पु
वत्स्यथा रे धर्मस्यापयेत्तवान् वत्स्यापयत्तवा संयुक्तविषये किं
भेवेरुमणीयीय तत्कर्म वत्स्यथैवा पुरुषे भैरवंलभय ल
भवा ॥ धातुसम्बन्धे ॥ धातूपगामे जातः पञ्चमी स्यात् भव
सत्तु ॥ समजगामि सिद्धे ॥ पौरे समर्थकर्मणि लिङ्गद्वयः सम
जगा सम्पूर्णसूत्रिय सूत्राप्तु सिद्धमी: तयीरजये जाते: पञ्चमी
स्यात् समसूक्ष्मयिपिवाति सिरंगीवत्तत् भवान् हुंवा ॥ क्रिया
समभिहारे सर्वकालेषु सर्वेष्वेकवचनं पञ्चम्याः ॥ क्रियासम
भिहारे वर्तमानाद्धातोः सर्वेषु कालेषु सर्वेष्वेकवचनेषु पञ्चम्या सह
सम्बन्धे एकवचनं स्यात् उभये विषये वा वर्तते सम् क्रियाणां सम
स्त्रयेत्तवा प्रवृत्तस्य पूर्वे दिग्रहणे हि क्रुत्तमेव समस्त्रयेतु सामा
न्यजन्य पूर्वर्थे वा हृष्टाय सर्व वर्तमानात्: क्रियासमभिहारे द्व
वाच्ये लुनीहि ३ लुनाति लुनीतः लुनन्ति लुनासि लुनीथः लुनी
थ पक्षे लुनीत लुनीतेति प्रयं लुनीथ लुनीहि लुनीहीति वला
वीत् लविषुरिवा अधीष्व अधीष्वेति अधीते इदमि इंविष
ये तपक्षे अधीध्वं अधीध्वमिति प्रयं अधीध्वे समस्त्रयेतु सक्तू
न्पिब धाना: खादेत्यभ्यवहरति सर्वं कुरुक्ष्व तिकमाश्रामदंहर
त्यवहरते सर्वमेतु पिबत खादते त्यवहरथ कुरुक्ष्व माश्रामद्य
मिति अभ्यवहरध्वं पक्षे सक्तून्पिबत धाना: खादति ॥ कुत
करणवहन्न ॥ गच्छन्दिरकरिष्येत करणसमते तक्रूटविव
जये पीतकालेषु: ॥ त्वांस्त्रसहस्य भि: कलविसेप: ॥ हः स्व
छतत्रीते हस्वनीहः पापमदरत् ॥ भास्मयिगहस्वनीस ॥

क-
क-
८१

माम्हहुगी ॥ नंभामाम्हयेगे ॥ थहुहुदिंडहम्हि यदगं
डवमृाङ थम्हिदम्हङि भाम्हठवङ थहृङगीहुगीङ भाभाई थ
कधीङ ॥ भायेगेहृङगी ॥ भाकधीङ भाम्हकधीङ ॥ थं
म्हा ॥ णंङेरगीङकलेडयंभृाङ थकेहः थथम्हिवगीङ थंम्हा
ङियरंमहरुदनहः मिङह्राकेपेपि मंङेदंकिलविललाथ प
हङ्गापक्फयेय गादंमृहृनंभहुले ॥ ठविमृङि ठविमृहृमीग्र
भङ्गः ॥ ाङ्गाठविमृङिकलेमृः ग्रःभुःहृङि ठविमृङि ग्रभुगीग्रः
कङ्गा थमीडङ्के ठविमृहमीः ल्लीयाम्हिवःठविमृङि भाभाई
ठविमृङीकविमृङि थठिह्लवमरे णङ्गावथपठीङेय म्हरमि
ल्वमङे कम्हीरंमृवह्रुमः। ह्रियाया थविम्हङिदम्हिंभङ्गजीङ
ह्रियाङ्गिपङ्गिः भठक्षिह्लमठविमृङ मिविंत्रमृदनकविमृङ ॥
ङङिमिवम ॥ ठहंपमृेभथमरेभठहम ॥ भभाभ्रामेयमा
ल्हाङपृकरल्केंभमीठहुगुमयंगेवठरजङ ॥ ॥ ॥

ॅविकमयत्रीकमल्लंमपक्कं नकंउमः अक्लामिउंमरेह्लु पक्कं
वेठडपमेिधयत्रीमरम्रुत्रीएहुमपाकरेउे ॥ णउेः ॥
पुण्किरेयम(पत्रएमिहूउःपाक(॥ मउम्रृंमपपप्ठम(॥
पम्मिगुडणिकरेमपम्रूउमझ्लाविउमपपप्ठमंझ्लुमूाउ(॥
उम्गूमयेउ(॥ उम्पपप्ठंणउेःपूाकूयेणुंनामझ्लेमूउ(॥
नउ(॥ पम्मिगुडणिकरेपूहयाःजमंझ्लुमूपिउिमंह्लुण्किरे
यम(॥ वाम्रंऊपेम्मियाम(॥ पूहविठिजऊपेपवाप्ठपूहयः
माभाहमूतण्केवापूाउ(मूण्किरेऊंविग ॥ उम्हासीयो ॥
णउेरउेम्पुः ॥ कउुरिजउ(॥ उम्हाप्ठयःपुल्लः पूाझाःपूह
याःकउुरिमूविठिशाप्यु ॥ उेजहः ॥ उम्हासीयपह्यप(पूहला
उवैकेकेटहुःनहमंह्लुपूः ॥ ठवकम्ल्लेःनहझ्लापलमः ॥
नहःझः(पलम्रु (पल(पूठवकमल्लेरेवपूः पूउमिपुहिः
मूपहि पणिउहम(मणीयम(हयाकउूहःकरम्लीयंहयाठ
मः वमःकउुरि उम्हउपणालीझम्लवमऊीिवापूहः ॥ कम
कउुरिणउेः केल्लिमरहयेवामूः ॥ केयडम्रुयेझवलम(॥
करवमूपूहयेणउेदपक्कदंमूाउ(येउऊियम्रुंडम्रुलयिहडु
ऊियडम्रुवाम्रम्रूपणगुल्लेन ठिमेल्लिमातिमाधाल्लिम्रुयम
वठिहूउेऊिायवंपमेल्लिमाःपापः ॥ नहूपूरेहूहपि ॥
क॰ नहपम्रुम्राजामठहपिपूःपूाहाठिःम्रांतीयापूःमीयउेम्रुमे
को॰
नउ मनीयःमूमल्लः ॥ पूराहः ॥ पूराउाहःमूाउ(गुल्लाजह ॥

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

243

[illegible]

नमिदूङ मिठ
नकाल

मधुं मंभूम। सहं तिहम। शहं गिहम। ॥ [illegible] ॥

[illegible] किं

म। [illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] । [illegible] । [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible] । [illegible]

[illegible] ॥ [illegible] ॥

[illegible]

[illegible]

॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]
[illegible] तिमिङ्गिलः [illegible]
लः [illegible] तिमिङ्गिलगिलः ॥ [illegible] ॥
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥

[illegible]

[illegible] ॥
[illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible] ॥
[illegible] ॥ [illegible]
[illegible]

स्यवडे भूमा स्यव:नाय: पुहंविदृमिभूडे स्यव:रयउडिउठवेकुयी

मकरकेस्वयवस्यगभीहला ॥ ठवडेस्र ॥ ठयु:ठव: ॥ समानु:

भूव:वेडिनिवडउभ संभाव:प्रभाव: ॥ प्रवेहूमे: ॥ प्रवदन:

पवभूडि पवभायडि पवभाय: पवेकिभ दरक:भारक: ॥ पु

देवा ॥ वापकेम पाद: पूद:हवभिडविठमेयभ उेन

हुपाद: पुंधिपाद: ॥ गदेहुका ॥ गदेहुकाभूउ गदेहु

गहुडि गदभ गहूड गदगन: ॥ मिलिनिवेमा ॥ चडिपानिव

ललिहापवधूडेकाइदेजनयुनं मिलनभभूनडक:पुपाक: ॥ वधुलि

वेस्र ॥ वले:पठभलेप:भूउ नालक: ॥ गोधक: ॥ गायुड:नि

न्दिविकउविचक:भूउ गाचक: ॥ हुंडु ॥ गायन: ॥ द:कलवीहि: ॥

पुडकाबदएवाहुएभूउकलवीदेमाझे लादडि लिदीडेहवुगद

यनाबद्धंलादडिलीदीडेवेस्यकभिडिदयरेहीदि: ॥ शुभिधूक: ॥

शुभिविनभूभानायंलाउेहु भादचरभक:भूउ लीवडउ लीवक:

नदक: ॥ भूमलेत्राभाएकविलि ॥ भवांभाएकविलिपक:भूउ

काइदभाएपूवेभूवक: चत्रु:भवकंभउलवक: ॥ कमदूला ॥

कमदूपपरुेणाउेला भूउकुंठकवेडि उठकर:भवनाभ्रेठडिभ

हुंवडव:ठवंगी पमुडिठवदनव: विकुंडायजीहदयवाठिणंत्रकुम

लिभाला ॥ स्त्रियायंस्त्रियाउयांकदलिसेपपदेठविधूदूला भूउगे

दयेहालाउिकाइलाविहुलाडि ॥ हुवाभस्र ॥ सह:कमदूपपदे

पूला भूउ भनकुय:उभुवाय:पहुभाय: ॥ मीलिकभिमविठ

किहूल: ॥ सह:कमदलिल:भूउ पतृपु:भांसमीलापुडकभा

कन्तुभ्रुभागुपवउुम ॥ गेंधिकभिहंस ॥ भापचगीक:ठउम

म: ॥ पुडेपभनाहु: ॥ कमदूपपदेउपभनाहुदनुमु:भूउ

गोद:कवलद: मयपभनाकिं पद्मभदय: ॥ गेविभुस्र ॥ यवि

त्रिपुरद्विः दः शृङ्गमभक्ष्यः॥ मांसविकृतिरपि॥ कन्दुपः द्विपःपा
दपः॥ शूकरोमा॥ शुक्रवाद्यदरितबाह्यक्रकदलि दः शृङ्गमु
कुरुदः पशिशल्लः॥ शल्यिष्ठः॥ भद्रपद्मकुरुः कदलि दः शृङ्ग
गोभक्षः॥ गोपृष्ठकः॥ गायद्दिगद्दपमनाङ्ग एकोशृङ्गकदलि॥
मामगः॥ उपमतेरुमामभक्ष्यः॥ भूरमीरुः पिवरुः॥
एकोशृङ्गमरायः मीरपः पद्दपमनाक्रिदेवपुराभृपायः॥ द्वार्थि
लुंघेरकृभवयेः॥ दरुः कदलि पमाशृङ्गवयमि पद्दकृमनेम
गाष्ठकवयदरः कद्वियकभारः शूक्ष्मिदरः स्वावेमदरः विकृद
रः मार्येः किंकरदरः॥ कुलिङ्गमुलिङ्ग॥ पक्षपुटदशति कुलु
लः पक्षदरः कुलुलिङ्गकिम कृपादरः॥ षडङ्ग॥ कदष्ट
मशृङ्ग प्रष्टहः॥ मुक्तकल्ययेः मधुभृङ्गयेवमिलपेरभृद्गः॥
दमिभूमकयेः॥ रक्तयेः हुद्रदपदरवरूल्लमिडिड्भुद्भवाद्धभृष्ट
पलक शुण्ठमर्दुरृश्वेरमः दशीकलेलपः भृमकः॥ ए
रः पुदरल्लमावदेष्टप्रदयेः॥ एलैरद्दपुद्भवलेपदरल्लकद
लि पुमभृङ्गवयलुगरः पुदरल्लडडिमवामृभलल्लरः उह
क्रिदवनाङ्गपुरुद्दिडम दरुघुडडिदवनाङ्ग पद्भुद्दिडिकम
प्रवगरः॥ गद्दद्रदकलाप्रलाङ्कुमक्षिमक्रिद्दिभविष्णुदेवा
लपुकदमगृदेवामाशृङ्ग गरनदः गरलादः उहदि॥ ष्पली
ष्पलयेत्र॥ ष्पलीपृदः ष्पलीकादः उहदि मधुवेहः मंहूया
लहेम शृङ्ग मंहूयामभक्षरः मंवदः मंहूयांकिं मंहदेडि
पुप्रकवति पवठिगनाङ्ग॥ मीरोठिकरल्ल॥ पिमडपिम
यः॥ पामुद्रिष्ठकरल्लपुप॥ पामुद्राहृमेड पामुमयः उष्ट
रमयः पत्रमयः उग्रनाक्रियकदपउग्रः मेडउग्रनमयः
पपाह्निङ्ग पपाक्रायः उग्रमयः॥ सूरेभुः॥ मरउरवि
करल्लेगृङ्गवरमरः गल्लमरः॥ मेरुद्दपिम॥ चाणिक
रज्जुदष्टर्मि मधातिक्रुंमवति तिक्तमरः मेषमरः पुदय

...पक्ष्मर: पक्षाक्षर: पक्ष्मर: ॥ प्रवेकंडूति ॥
कण्डूः प्रवमक्षे भडूः ट: [illegible]

मर: ॥ [illegible] भडूः ॥ [illegible] भडूः ट: [illegible] प्रव: भवति प्र
वमर: कडूति किं प्रवंदमं भवति प्रवभाव: ॥ [illegible]
[illegible] ॥ द
[illegible] ट: [illegible] भः
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] कर: [illegible] कर: [illegible] किं म
[illegible] कर [illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible] ट: [illegible]
[illegible] कर: [illegible] कर: [illegible] कर: [illegible] कर: [illegible]
कर: [illegible] कर: [illegible] कर: [illegible]
[illegible] ॥ [illegible] ॥ कम
[illegible] कर: ॥ [illegible]
[illegible] ॥ [illegible] कर: [illegible] य
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
क [illegible] ॥ [illegible]
को. [illegible] ॥ [illegible] ॥
४३ [illegible] ॥ [illegible]

श्रुः श्रुतउ शुचिस्तुपः शुचस्तुपः उ इति ॥ गन्धीकरभोभिधान्निना
भिकमधम्मव ॥ नथकदभणेदुः पमश्रुतउ घ्नव नाभिस्तुपः
नाभिस्तुभः उइति ॥ वदविश्वेदभिलेषत्तुदः ॥ पमश्रुतउ
तुत्कदेवनीदगुल्लं वदस्तुदः विश्वस्तुदः भागभेदजेमयेगादि
गुणउडिभलेपः पदस्तुदः डिलस्तुदः ॥ वाजमठयेरणाल
दडिहूं पमउपमङ्घभ ॥ वाजभल्लदगा मठभयाजम
हूंणदडि मठङ्गदः भाषाः ॥ पभ्रदरोदेमः ॥ पभ्रदेउ
गेमकदलिभ्दमः पमश्रुतउ भ्रदंतथुसङीडि पभ्रदम्पदंत
गलदतः उगंथमा पभ्रतभः ॥ ललाटेउपः ॥ ललाट
गुथः उपतः ॥ भिउताथथविभालिधपत्तिः ॥ भिउम्दभःत
भ्दमः डिदतः पद्मभुउङतः पुशुम्दमः भरिभ्दमःक
दः ॥ कलउदगीद्वदेः ॥ कलेकदलिउदुचयेदणाव
देः पमश्रुतउ कलथद्गणीदि कलभद्गणः कलपद्मदः ॥
वंदलिदकंलिदेवम्भदव ॥ वदंलकि वदंलिदः पङ्कलि
दः विधाजगठगुडव उवयालेलेनभाङृतिमीषुडे पविनु
नहलिडि उदंमदेमुथपूति कुवलिपमविकवनडवथवति
पाहडे ॥ वदे पे प्रियवमयेः ॥ प्रियंवदः वमंवदः ॥
मङ्कथवभाये ॥ चायेविङ्गगाथे पमश्रुत दवेउवजनः
मङ्कधवंवाउपयति मङ्कुउपः मनस्तुपः ॥ धवंदेववामयमडि
धउपाव ॥ धवंदवयङीडि पल्ल धवभ्दः तग्रैदयः उपपद
सुभागभव्रविभाहडेवामं यमस्तीहल्ल मीडदवेवामेमाणाभ
सुवामं यमः वउविघुयाथाये द्विधंउपयजीहल्ल दवामा
गामेद्विधउपः ॥ मर्वेकलाहकृतीवमकथः ॥ पः श्रुतउग
वक्कथउइति ॥ ठयाडिमपेथवादः ॥ ठयकरः उम्दउविति
गा पकठयकरः ठडिकरः मेध्यकरः ॥ केमविपमकदेव्रम्म ॥

[illegible]

पृथक्पाकः । पः भूत् । [illegible] ॥ [illegible]
[illegible] भूमि [illegible] ॥ भूमि [illegible] पः भूत् । [illegible]
[illegible] भूमि [illegible] भूमि [illegible] ॥ [illegible]
[illegible] संख्यायाम् ॥ [illegible] पः भूत् । संख्यायां
विषये [illegible] विषम [illegible] विष्कः [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] पः भूत् । [illegible]
[illegible] ॥ [illegible] संख्यायामपि ॥ [illegible] भूत् ।
संख्यायामसंख्यायाम ॥ [illegible]
[illegible] संख्यायाम्
[illegible] संख्या
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥
[illegible] ॥ [illegible] भूत् । [illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] भूत् । [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] भूत् । [illegible] ॥
[illegible] ॥ [illegible] भूत् ।
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] भूत् । [illegible]
[illegible] ॥ [illegible]

[illegible]

नश्हकुद्रकेर्धम ॥ कदलिदत्ते: एकोश्हुड(प्रभरश्हकुद्रकेञ
पिडश्रृंध्यङ्ं प्रभरश्तृडिकिं श्रापध्याड: फुद्: नगांदत्ति नगार
ध्याडे दस्मी डदनेश्तृडे ॥ मञ्जोदन्त्रिकेवाएये: ॥ दत्तेश्हुकश्हुल
मञ्जोगाश्हाया दस्त्रिश्र: नर: कवाएश्र: मोर: ॥ पालिध्य
ज्यदुध्योमिलिद्धिति ॥ पालिज्यदप्रवादुत्तेश्हुक(ध्यङ्हश्रग
फिलैपातिपाहुत्रे मिलिद्धिनिकिम(पालिध्याड: ज्यदुध्याड: ॥
गाएध्यश्हुडयभश्हुभ(॥ गाएंदत्रिगाएध्य: ॥ नग्रपलि
उश्रियाप्रश्तुलभठगाकेश्रुकुडडफ्तवेनाफ: श्हलेकरल ॥
प्रडघाफुडश्ह डघाठवनभफुडडफुव: उश्निज्ञश्हेपश्रनाफ:
श्हुलेश्हाड(करलीकुडरिश्हपु: प्रनग्रं नग्रंकरेत्ति येनभाग्र
फ्तरल: उपएप: प्रवंपलिडफ्तरलडश्हाफि ॥ फ्तव: पि
श्लुापकफिकुडरि ॥ नग्राफिश्रुफुडडफ्तवेफुव: कादेडो
भु: प्रनग्रेनग्रेठवति नग्रंठविफु: नग्रंठवक: प्रवभश्ह ॥
क्रिश्रु ॥ ठडे: क्रिभाश्हाड(डापायांभ्भडे डापाभड(पल
श्रुड(मवनेडिगा: ध्यडध्यठक(ध्याश्मेनफकेडपपठेश्हल(
प्रव उफकध्यदन: फ: श्रयफु: ॥ नदेठवा ॥ काविहेव
वीनड(वीनठो श्हुवश्रिडविकुश्रुश्हुद्रिमफेनदेविहंदद
भवेफल(भवेनदो ॥ ठश्रिगफएफुगिश्रश्रिदश्र ॥ ठडो
यएडीश्रिाप(ठश्रिक(श्हपे: क्रिपिद्रिवमपं नएक(म
एवकरनाम: भक(फिश्हुड डडिकदलिक्रिपा फिका(उद्र
वश्हश्रिदडफेदलेपेविपाहडे उश्रिक(वाभड्रपनश्रश्राफि
विपाडनाभश्हड ॥ कदफुपभानेहफलेदमेश्रुफाकेम ॥
उपभानवामिनिकदलिहफफदपपफेदमेश्रुक(भकोप:
क्रिश्रकदश्हुञ ॥ प्रभेवाश्र: ॥ दश्रुभफकेप ज्यदम:

पालिध्य: ज्यदुध्य:

मंफ

लिश्रुध्यश्हन्हु

[illegible]

[illegible]

कृतिकिम। यथ्रयतिवाडि ॥ वृत्ताठीकृयस्त्र ॥ नाम्रिणउक्ति
(तंफहे।) निःशृउ। वृउ वृठीकृम, वसकृकुली, भाभेयवाभी, धीनःशृहेकी
यायियि, उमीनरः ॥ भनःपेवत्रार ॥ नाम्रिभहृउक्तिनिःशृ (भनकृते)
उ। उघाकृउभतिउयपप्रंशूलिंकृपवकृउ, मनीयभूभीन
मेठनांभहृउ मेठभातिनी भाश्री भाणभातिनी ॥ पिङ्गाङ्क
भाने ॥ नाभूाकुभाग्रकमहृउः। यमा। शृउ। लिनिस्त्र मठणभाकृ
नंभहृउभठणभहृः भठणभालीमीअहीडि हम्तः कलिंमहृक (नेहृपी)
[illegible]

[illegible]

मंक्लेशः ॥ विष्णु ॥ तोऽरगोऽविष्णुश्रीऽ, ठवकम ल दहऽङोठि
वकमले: ऊः कउरिसडिऽऊवउः उऽमदिविष्णुः सिवेवि
ग्रहऽवान ॥ घुहकमद लिविष्णुवकऊहा ॥ घुरिकेमद लिऊ
ग्रहकउरि ॥ कमलः प्रूसरिड्यःऊः अकउरिश्रीऽ माऽ ठव
कमल ग्रह प्रडऽः कदंमः पडऽः कलमेव प्रवउऽ अमब
ग्रहिकमहृऽवाऊः ॥ नेवंमकेठवऊः ॥ ग्रहंमकविधयेठव
ताऽः ऊश्रीऽ दमिऽऽन घुमिऽं ॥ गहऊाकमदकाग्रिवमीग्रह
मवमरुदलनलीदऽिहग्रह ॥ गहऊेपुषाकमदकेहः घुग्रहवाऽ
ग्निवः मीलविहग्रहऊः कउरिश्रीऽ ठवकमले ग्रह मन्देवाऽः
याऽः ऽऽः प्रयुः मः एगरिऽः लक्ष्मीभाग्निवः ॥ मीऽड्रहवि
ग्रिविविग्निविमिठवविष्णुभल ॥ तथाविष्णुश्रहयः भल गुल
श्रीऽ घऽिमयिऽः मेऽम ॥ हरिश्रुऽिभाभ्रंऽगुल ॥ तथा
भुहरवंश्रीऽ घगुलऽऽउयभिऽ गुरुभ उपासिऽवा ॥ वि
ष्णुयांम ॥ कठिवभोविलश्रीऽ उयोविऽ लिकंमहमीभ ऽऊ
ठेवमम घगुलऽभानविकम ॥ नविष्णुऽ नेवंमकिमवि
ग्रहग्रहः ॥ नेठमहम श्रीविष्णुऽकरमहः श्रीऽ पडऽहवि
हः परमऽन घगलीलिठदं कीरुः कीरुवान यपडऽह
रिकिम प्रऽः प्रऽयान गन्त्रेश्रीयिविऽिकलेयः ॥ घुलव
नुग्रह ॥ घुलवनुग्रहुऽविष्णुयामिललश्रीऽ प्रऽः प्रऽयन
ग्रहऽः ग्रहऽः ॥ घुऽेऽऊाभेयऊऽ ॥ घऽमंमयऊमऽः
परमृविष्णुऽमहः श्रीऽ प्रहानः विमलः ग्रानः ॥ हिमव
नुमऽिवग्निप्रलऊेहग्रहऊः ॥ हिमवनुहिमठहऊहग्रहवऽ
भानणभ्रूऊेः श्रीऽ मऽिविग्रहविठधापवृऽि एग्रहः ॥

वविऽऽरेहलीऽि मनग्रहऽिऽहध्यपकमलेयः ।

लम्बुवसृश्रक: ॥ लम्बुवसृत्रिषु स्मृत: स्मृत(प्रवसृलसृशभि
त्र: तंष्टुभज: शङ्कु: प्रलिङ्ग: शमसृलसृशपिवत्रभावेक: सीलि
ड: शलिड: ॥ त्रिषुपयांश ॥ स्मीलक: स्मृत ॥ स्मीलीकेड ॥
स्मेदेमीलकभुम्भ त्रिषु स्मृत: स्मृत(स्मीलवास ॥ लवकमल
मीक्रेनेमृड ॥ लिडमतेन लिड: कणिमया शुहमलेट्टमवाङ ।
लिडपय: मीशुपुवा ल्लम्: लेद्दलिड: मीलवादंमकलतृ: ॥
नमृतबलमृतं कवत्रु ॥ यथामिलत स्मृत कतवत्रुसिड: सिड
वार्त ड्ड: क्रुड: लड: । त्रासिद्दलकविंमति: लमवत्रुत्रिषुति
भुत्यस्मृत: स्मृत(त्रत: प्रत: द्रुणीत: लदक(भवीत: दलिकशु: ॥
तदीत्रीलदवत्रुवलमयतिनित्रिषु: ॥ सीद्रीलत्रवत्रुतांडमावे
लंमनित्रिषुयामिलत स्मृत(पोत्तिशुवकमयवितार त्रीत: त्रुद्री
तवात(लमतवत्रुत्रिषुलदं मल्दलीक: सृत: लीयु: प्रक्र: वेल:
लङ्क: मानु: मृत्: पपतीत्रिषु: किंपलिड: त्रिषुलिड: ॥ लवा
लिकमलच्चा ॥ पुलतवत्रुत्त्वलिकमलिमनित्रिषुवेल स्मृत
मितं मातिडं त्रितं त्रुतिडं भमित: भत्रित: ॥ दवयलमल्दलयें: सृ: ॥
दवसृतवयुत्थलतदं मल्लतवाङ मेदेतित्रिषुयां मंभमावल स्मृत ॥
सृत्मंदले ॥ मेदेतित्रिषु स्मृत: स्मृत(पमदलेडसीक: मीतंपड
पमदलेकिम मीतंलालं दवयलमदमयें: किम(सृतेमदेवलङ्क:
गङडङज: ॥ भुडेत्रू ॥ भुड: पवसृमेदे: मंभमावल स्मृत(त्रि
षुयां भुडिमीत: ॥ वाहवाहम ॥ भुहंपृ: मंभमावल स्मृत(
वापडिमीत: पवसृम: पवमीत: पवसृम: ॥ पापालत्रे: ॥
पत्रेत्रिषु स्मृत: स्मृत(रुपालने ॥ उलवत्रुप्रक्रिमांद्दि ॥
उलवापृत उतिवेत्रुतेलमभक: पयालवेउ उलजप लकं

Marginal notes:

नीलमणि किकर्य

रुपालने

त्रिलमिवार्यां उम्पुडी कुमपुर्यां वालवल त्रालकेमने त्रालकम्दने लदकाहाने नलीकम्

॥ त्रिडीलवत्रुलत ॥

नीलविदयमिगङो दाजद्विगडिया कु: मीपीमीश्रीपमीत्रुपायें मल्लमने

ममउपममपुलमंबल पड्डागडो

लित्रिलपदेरमेदनयें:

मलूपाराजानामिहदं पुडेङ्गा उविहं क्षीक्षमनुसिलिपतने वामीक:।

क० कौ० ४१

मोहना हृष्मवे नेपा

[illegible]

मधतिकार्यं

अथ: मेष्विभुाभदय: गुल्मीभृगु मछिड: ममायांकिम पृष्टचिरं
वाक्मभाद ॥ ठवाल्किकमल्ले वेदपणाउ ॥ ठवेपुलिकमल्लिमउ
करविशुभटय: मेलेवागुल्मीमृाउ मूर्तिर्ज मूर्तिभवेन भमूतिड:
मूर्तिड: उदयणार्कं लिाष्टउभवेन, प्रविकल्पेष्टामवेमूर्ते गुणि
उभवेन शशुणिड: ॥ निभुलीनं: ॥ विभुयायउएउम्मिदरकाति
उम्रेवेलेप: मृाउ पामिड: ठविड: ॥ श्रेष्टल्लवेयु ॥ यवयेरय
हृष्कवेलेप: मृाउ क्रयीक्राउ: क्षयीक्षउ: ॥ क्रठिवाजिश्रवतिशति
ठल्लिकधिष्यधां क्रमेदक्रष्टममनमुभेनायाभजक्राविमक्रवेषु ॥
कृकलीतांभक्रम्भिषुजेषक्रभटयेउमभृाउ कषुभक्र: कठिटेटे:
उर्फं ढमं, वादिउमहृउ श्रागुंमर: श्रुतिउमहृउ ढकुमरायाभल्
उमोयणभ ढल्लिउमहृउ कभुं लक्कं कषिउमहृउ ॥ लग्रश्रिभुवि
विभु: मक्रविमदभुश्रवेषु ॥ लप्रंमक्रं उदठवेविभुाठंम श्रिभुम
विमदभुभ उदठय उपणात्मभज्ञ विविभु: श्वर: उषातियाष्टउप
टउलागिउ: श्रक्षिउ: विरठिउ: ॥ पतिवल्कपतिमल्केमकुव
लवेउ: ॥ उदठवेलेपतियाउनाक्रमिमदम पत्यै: किम ठंदि
उ ठंदिउं ॥ मंतिविष्टिमदः ॥ मठ: पुरमृाकेतिल मृाउर विभु
यांममल्लु: मठ: किम पद्दिउ: ॥ मामीष्टठ: ॥ पुठ: पुरमृा
ठू: मृाउ मामीभजे पठल्लु: पौठिदिउेटु: ॥ वादभुमहृ
रमक्षुपाश्रराम ॥ पक्षांविभुायामिलेवामृाउ मभु: मथि
उ: पौठिमिउ: पठउ: हृणिउ: सिह्वीउि क्रल्लु क्रल्लु: मक्ष
विउ: मक्षभु: पुभुतिउ: पुभाउ: ॥ ठवेक्रमम ॥ ठवेभु ठ
धिउं लेम ॥ वाटुमाउपठपुमदभुक्रलाभा: ॥ मनि मनि
श्रविश्रमिचुआंउउदठथवातियाष्टउ मठ: ठमिउ: माउ:

Marginal notes (left): उपपतिवधूनउदमृक्केकाति कद्धउउपणागुलेन। — मेनभृाउन श्रद्धकपटक्रपांवाति रहमटु। — ठदिठदिटक्षु ठदिठपाज: पतिठवमूलं उतिवाणम:। — कयरेधरथवद्वाउ उिवा पमरेप भुद्रिमद।

Marginal notes (right): ^ श्रागुंउम: श्रुतिउमहृउ — ^ पभुमविमदजमवरे दमवरे पषिउमहृउ ^ — मठुवभृषवद: उउि नटे नथवलेकी: उवन स्रुटि उि नमृ: । — ठथठक्षी

Interlinear glosses: उपणाद्भीत्र: — सीउ: — ठधउपठप पमगाएनमनरउे: पमनदल्ली उडिवा

Below text: उतिपमूवतितिसीत्र: उव ठवाति एउ।

Left margin at foot: कृ. को. पउ

[illegible]

हवेनियाहङ्ङे मदेकयणसीडङ्ग्न मिदिदमृहङ्म ॥ गमदनवि
दविमद्भमांवा ॥ वमेवेल्भृाउ\ णग्मिवान\ णगाङ्गान\ णग्निवा
न\ णगाङ्गान\ विविमिवान\ विविङ्गन\ विविमिवान\ विविङ्गान\
दद्मिवान\ दद्ङ्गान\॥ वडुभानेमङ्गुङ्गुनमेषा, यवमाङ्गिवणि
कराश्रमङ्ल्यैः ॥ णङेचडुभानेमङ्गुङ्गुनमोभुः यवमाङ्गामामा
नणिकरहुमुमङ्ल्ल्म यवि पमडुं देयवदङ्गं पमृ ॥ तेनगुल्ः ॥
नकुवेवङ्गुमङिगुल्नभृाउ\ भुवङ्गं मामवगदल्दवे ॥ भुवे
हृद्वे ॥ णयवक्लुलियकरभुवमेभुङ्गतेपदमंल्भुः ॥ भुद्वे
भुवे ॥ यकवधदवम्भिङ्गनेभकवनामभृाउ\ पवमानं पमृ भुङ्गि
भुवानवकमाम\ मंवेणे देपमव\ पवमानवानामु ॥ मामदवे
नाथवमामामानणिकरहेथि मङ्गहङ्गुमेभुः भुवमेङे मालो
वन\ माभेवमानः यङुभेवालोनः ॥ लमाल्देङेः क्रियायाः ॥ येन
क्रियाल्भृाउ यङ्ग क्रियायादेङुभुाद्मेणउँवडुमानाङुङेः मङ्गु
ङुनमेभुः । भुवानामदकिमङिदमङ्गेथ्यवेङिदलनाः देङे, प
ममानपियामडुः मेवमानाः पलामपि विभूनपिथमंमङुः यवया
मेदङेदवम\ ॥ वङुः मडुवद्दः ॥ वङुः पवभूमडुवद्दः भृाउ\ वाङे
वाभृभ\ विङ्गन\ विदन\ ॥ रेङभूामंः ॥ भुमः पवभूङ्गवभूरंकमः
भृाउ\ पवकदेविकदामिः भुमीनः ९पः हङिग्मनङे\ ॥ मङ्गु
नेभृमंदिङेमेथेम ॥ णङेडविभृङिकाल्ले मङ्गुनेभृन मदिङेभुः
क्रियायां क्रियाजायां मदामममङं म कांकविभृङ्गणङि कविभृ
मानेवा मेयेयथा उपकविभूा\ उपकविभृमाल्वा ॥ यहल्लेः
मानवल ॥ पवमानः यलमानः ॥ मङ्गिवयभुाङ्गुल्लिे ॥ णव
कु· नाहृथणङेः मानवल\ भृाउ\ मङ्गे मङ्गुं निथ्यानः वयलिकयमं वि
को· हल्ः ङङ्गुल्लि कथयमानः ॥ ङहविहांमङ्गुहङ्गनङ्गु ॥ ङलः
५७ \ङवाङ्गकृलम्न मङ्गलभृाउ\ पवमङ्कु हङे मणीयदवयल्ं णवयदं

मङ्गाङ्गुङङिङल

लीवङुल्लणमल्ल मेदमेवन

एलपवनमुानं

पूर्वस्मिन् किम् [illegible] प्रतीते णयति वा ॥ स्त्रियः मन्त्रे ॥ [illegible]
मन्त्रः ॥ [illegible] ॥ [illegible] किम् [illegible]
[illegible] ॥ [illegible] ॥ [illegible] किम्
[illegible] ॥ सनाशंसभिक्ष उः ॥ ॥ [illegible]
चिकीर्षुः आशंसुः ॥ [illegible] भिक्षुः [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] भिक्षुः ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] धारयिष्णुः पारयिष्णुः ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ ग्लास्नुः जिष्णुः स्थास्नुः भूष्णुः ॥ [illegible] :
[illegible] ॥ [illegible] ॥ [illegible] घिनुण् ॥ गणात्रिकक्षयां (?)
त्रस्नुः गृध्नुः धृष्णुः क्षिप्नुः ॥ शमित्यष्टाभ्यो घिनुण् ॥
शम तम दम श्रम भ्रम क्षम क्लम मदी एषां घिनुण् स्यात् शमी
तमी इत्यादि उन्मादी ॥ [illegible]
[illegible] ॥ घिनुण् स्यात् योगी रोगी [illegible]
[illegible] द्वेषी द्रोही दोही [illegible] त्यागी रागी भागी [illegible]
[illegible] ॥ [illegible] ॥
घिनुण् स्यात् संपर्की [illegible] : [illegible]
घिनुण् [illegible] : [illegible] ॥ वौ कष
लसकत्थस्रम्भः ॥ विकषी विलासी विकत्थी विस्रम्भी विका
षी विलासी [illegible] अपलाषी ॥ प्रे लपसृद्रुमथवदवस
लपाम् ॥ प्रलपी प्रसारी प्रद्रावी प्रमाथी प्रवादी प्रवासी ॥
परौ [illegible] ॥ परिसारी परि[illegible] [illegible] विसारी संसारी

उपपदः

विदची ॥ निंदहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि
व परिक्षेपकः परिराटीदृति ॥ निंदहिंसक्लिशखादकव्याभावि
नाशकृतधातुभ्यो वुञ् ॥ निंदकः हिंसकः क्लेशकः खादकः वि
नाशकः विनाशकः परिक्षेपकः परिराटकः ॥ देविक्रुशोश्चोपसर्गे ॥
आदेवकः आक्रोशकः उपसर्गे किम् देवयिता क्रोष्टा ॥ चलनश
ब्दार्थादकर्मकाद्युच् ॥ चलनः शब्दनः अकर्मकात् किम् पठिता विद्यायाः ॥ अनु
दात्तेतश्च हलादेः ॥ वर्तनः वर्धनः हलादेः किम् एधिता ॥ जुचङ्क्रम्यदन्द्रम्य
सृगृधिज्वलशुचलषपतपदः ॥ जवनः चङ्क्रमणः दन्द्रमणः सरणः गर्धनः ज्वलनः शोचनः लषणः पतनः पदनः ॥ क्रुधमण्डा
र्थेभ्यश्च ॥ क्रोधनः रोषणः मण्डनः भूषणः ॥ न यः ॥ क्नूयिता क्ष्मायिता ॥ सूददीपदीक्षश्च ॥ सूदिता दीपिता दीक्षिता ॥ ल
षपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ॥ अपलाषुकः ...
॥ जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥ जल्पाकः भिक्षाकः कुट्टाकः लुण्टाकः
वराकः ॥ वराकी ॥ प्रजोरिनिः ॥ प्रजवी ॥ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥ जयी दरी क्षयी विश्रयी अत्ययी वमी अव्यथी अभ्यमी परिभवी प्रसवी ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥ स्पृहयालुः गृहयालुः पतयालुः दयालुः निद्रालुः तन्द्रालुः श्रद्धालुः ॥ दाधेट्सिशदसदो रुः ॥ दारुः धारुः सेरुः शद्रुः सद्रुः ॥ सृघस्यदः क्मरच् ॥ सृमरः घस्मरः अद्मरः ॥ भञ्ज...

क.
को.
१०.

मिकन्हुंध्वरः ॥ मेदुरः दन्तुरः दन्तुरेभ्वयमेव दन्तुरः ॥ विवि
किकिस्मिकंकुरः ॥ विदुरः किदुरः स्किदुरः ॥ मलीनमांध्व
रधः ॥ मदुरः लिदुरः उदुरः नदुरः ॥ गमभूम ॥ गमद्ध
रध शृङ्ग भमृदस्व गदुरः ॥ श्यगङ्कः ॥ श्यगङ्ः ङ्कः शृङ्ग
श्यगङ्कः ॥ महीयिकनुनांयलिलपिमज्ञिवदभ ॥ डकः
शृङ्ग यायलुकः गदिङ्लपडिडस्त्रीलः लङ्कभ्रकः मदमु
कः कवदकः ॥ डडेयाडेवरः ॥ महीयिकनुङ्डेवरः शृङ्ग
पमृपलेपः दस्त्यलेपविणिंशडिश्वविवडिडि ष्वनिवञ्ञ
वाह्निष्टृ्ञ्ञवेयेडडियलेपः यायावरः ॥ कमियिमिकमीमधु
थुमदंम ॥ वरः शृङ्ग कम्वरः येम्वरः कम्वरः येम्वरः श्ववरः
थुमम्वरः ॥ मीयिकम्पृलमिदिमिकमिम्मिनमांरः ॥ मीथुः
कम्पः लभिनाकुवः प्यलभम मस्यमिदमः दिथुः कमथुः स्व
वः नमः ॥ मवङ्मंमिकिकमुः ॥ मवङ्कुङ्डुवमेंमंदिक्वि
स्नुवद्वहयशृङ्ग मिकीवुः थुमंपुः किथुः ॥ विद्विमुम ॥
वेङ्गागमडवेमुङ्कुपश्वहयेयिपाहडेवडि दस्त्रीले विमः डकुः ॥
थुमवञ्ञपणलेपिनांकिम्बुम ॥ थुदजामवनुमांगमदेकु
पणलेपिनांमकिः शृङ्ग मवाङ्मिमथुः पपिः मेमम मदिनाः
वञ्ञिवङ्भ लग्दिङ्वा लम्रिवङ्भ लक्रिङ्गलभ ॥ म
दिवदियलिपडिकस्नुनीयिकनुक्रः किवामृः ॥ ममदिः
वावदिः मममलिः पापडिः ॥ ममिकमिम्मपांनलिल ॥
मङ्कक मम्नुले वङ्कक सुम्रक ॥ मनवञ्ञिहामानः ॥
ममनः मङ्नः ॥ किंयिनस्नुकिम ॥ ठीनः ठीलः ङ्कल्ला
कावपीमुडे ठीनकः ठीलकः ॥ तुडिस्त्रीलामिरकमः ॥ ॥
डिकुयेकुविमन्दुम ॥ मम्वपपमेधुञ्ञवेकुः भृङ्ग विकुः मकुः
थुकुः ॥ कमनिहलः भूमा ॥ [illegible]

धिधाविबुक्त

उडिणङ्गी ॥ नीदध्वमययुगलभुङ्मदमिमिममिदपङ्दंमनदः
कुवलि ॥ मद्दः करालजिह्व भ्रूमाङ्गीयङ्गेनेइभ दइभ ॥
धपवद्विन्नदङिङ्इइलनुदल्भृणिङ्गादद्दइपिलगीशिमिणः
मनृयिइभ येक्रं मेइ उेंमेइभ मह्रं मद्दृभ यइं दंभ्रा नह्रु ॥
दलप्रकरयेभव: ॥ प्रएःप्राकृत्न करालजिह्वा भ्राङ् उम्न
कुलंदलप्रकरये: दलभृप्रकरभृवा येइं मापमिइऊ: ॥
पङ्गिनङ्गाप्तिमदिमरिहृङ्ग: ॥ परिइंलविइमिइदि ॥
भव: मंल्लयाभ ॥ प्रङुदि: मंल्लयांउमापविइमनाभयेधुन
भ ॥ ठपिदिवयेन्नकङ्गि ॥ भवङ्इः भृङ् कङ्गिठधिदिव
येरजये: पाइंजलभभाणरपविइंङ्गिणभङ्गम: पद्रि: पवि
इंभमांभवाङ्ग ॥ भवये: किं य: प्रङ: मभवाङ्गभाभ ॥ ॥
उडिङ्गुमिभूकम: ॥ मिजवापालिमिप्रुमिमाष्टमुहृङ्ग
वासृ: । करेङ्गीडिकम: वाङ्गिवायु: पाङ्गिपायु: रुयु: भायु:
भाङ्ग: भाषु: भुमु: ॥ मिङ्गिनिमिमभिमभृविणहृभुग ॥
मिदि मेङ्ग: इइङिनल उङ्ग: गङ्ग: भपु: भमृङ्ग उडिमकु मिमृवीडि
कुल डङ्ग: णङ्ग: ॥ पन्निप्रुविमयिकमिहृङमि: ॥ पंन्नि: मेधि:
भदि: उमदङ्गिडिदुश्च: कदि: भवणङ्गहृमग कदम मदम ॥ भय
उरहृश्नमदिलिपङ्ग ॥ भिविवीइल ॥ उदंमति ॥ भङ्गम
लेप: भृङ् दद्म ॥ धुङ्ग ॥ भभंवभंदुभ्व: कइभ ॥ मृद
किमदुदिगदिहृभुगृ: ॥ मवायृ: यङ्गभमु: मकयेगदः
नान्तिभ्रुपृति नेलेपः मदुदयायृ: गदयायृ: ॥ भतिदधि
भविगमिभदिहृडबेहृङ्ग: ॥ भवपिङ्ग: ददयङ्ग: पेयपिङ्ग:
गमयिङ्ग: वावङक: भमयिङ्ग: भदिग ॥ लुधिमिहांगम ॥
युवगाभगकङ्ग: ॥ लगङ्गे भदिष: वेमङ्ग: हङ्गुवदिवमि
ठमिभाति गडिमङ्गिलिनदिहन्न । अङ्ग: ठवङ्ग: वदङ्ग: वभङ्ग:

भदमंमत्त

कु. को. १०

कमतुः भणतुः गदेडणमिश्चिनभावबद्धहाङ्कुम्बः गाम्बिक्ष्णूणतेतु
श्रिगिनकरिडलेपः गदयतुः मङ्यतुः णयतुः नस्यतुः ॥ गम
विवि: ॥ गभी। पुम्हिडण्डुडु। पुगाभी ॥ कुवन्न ॥ कुबी। पु
म्रुः ॥ पुकुयी ॥ गम्बपयणेपत्रेफचामृः ॥ ड्क्ष्मीणदम्बयः ॥
हक्ष्मीगंमणि:कणेभुः डेधांमहेयभ्रमदकरमुष्टयः म्रा श्रुपिवमि
ड। हक्रुः ॥ पुविभूमिड्सुकः मलेपन्न ॥ यङ्कवाड्मड पु
मिदमभन मद्‌भण्यां
मदवि मम षः मदः कूगः मेथ्यः मेथ्यः पञः ॥ उणुमयकुडपि ॥
णडेषुभानेकलेउणुमयः पुटयाः घृः कुडपि वडभानेका
ले करेडीकणः कुड मणिडं मम ॥ कविभूडिगणमयः ॥
निपाहेडे
गभीहमयः मरुकविभूडि भाणवः गमिभूडिगभी ॥ हम
मेधोभमुणने ॥ पडेभंभूणेककेविपाहेडे णमहंभम
मः पहाम्यमाहुण। गाः थहम्भे गेधोडि विः पडमयविपाड
माड। एक। ॥ कीभामयेपार्दने ॥ विकीहम्भकीमः कीपः
कियः पत्रेगिमृगडमयविपाडमाड। कयानकः मुरकपुटयः
मुवहम्भमणं पुवः कः मुवहमाडगिकियं। मुकं ॥ डहाभ
हडेणुमयः ॥ मम्भुमनायामणवाहाभहडकमेकारकेउणु
उम भा
मयः घृः डडड डेनुः वडंवमयविडंमम ॥ डकुणुमिडकमः ॥ ॥
मिम्भुफेधुककणकेपडभं ॥ उम्भुडि याकुडि कमयडेवश्रिवा
केडुभं। म्भं ॥ मकणेषहुणाथ्यणेकलकहमभदहाभुड
षडुभं ॥ मकम्भिब्रभूफेधुमेपपमेषडुभं। माडं मकेडि केडुं
मवंपधुडिडहमि पमि विहडे कवडि याकेडुभं ॥ काल
मभयेवेलामकृफेषम ॥ कलाफेषु मकृकेषुमेपपमेषुडुभे
भाडं। कालः ममयेवेला मनेदा मयमरेवा केडुभं। मकृः
पदापुः ममफेयापणिडभं। मामहृडापि उमिडभं। उपयत्रंपु
फुं माम्भडभं। आडुभं। डंकाभमनभेरपीतिडुभेमहलेपः कडु

कमः रन्तुमनाः वस्तुभोक्तुमिच्छायामिति तुमन्तं वक्तुं पठितुं वा इच्छति ॥
पक्ष्मणो विसर्गस्य मिसोर्थ्याल् ॥ पठति पाठः गणेति रोगः वेगः
स्पर्शः स्पर्शकः ॥ भुः स्थिरश्रान्तिः ॥ भट्टे स्थिरे स्पृष्टे भावे ख्याल् शू
ल् भावः ॥ ख्याले णत्वे नामृत् स्पृ पमन स्पृ वकुलं स्त्रीत्वे वामृः ॥
घञीभावे स्पृष्टिः भकृवलये रपीभूते विभावे भकृः भावे वलभ ॥
ठवे ॥ णत्वे णत्वः ख्याल् भाउ पाकः पाको श्रीदरः नामृतु
स्पृ पमन स्पृकमस्त्रीत्वे वामृः नीकमः श्रद्धके शुश्रीकमभ नामृ
तस्पृ किंश्कामः रमेण्डे नस्त्रीत्वः ममः उमः वभावेषु कामः
कमः पुमामः विमुखमण्डे त्रिभावत्व ॥ स्पृष्टित्वे ॥ ख्यातिय
पुमल्लेपः भाउ स्पृष्टिलेव पवर्गस्पृकः ॥ स्पृष्टिभावाद् ॥ स्पृ
नामपुत्रः धंसिकरणात्किरल्ये त्वाद् भाउ ॥ ख्यातीतुः ॥
पक्षमल्लेपः भाउ पणः भभित ॥ पवेस्तत्त्वे ॥ पवेत
पपदे स्त्रीत्वे भाउ धंसिकरणात्किरल्ये पवतस्पृष्टिष्ठ
पवतरः पवभारः ॥ पकारमिकारके भंगुल्याम ॥ कस्मिन्
कारके ख्याल भाउ संगुल्यां ॥ वल्लिवकुरल्ये ॥ ख्यातिपंस
मल्लेपः भाउ गगः पवर्गे किं गदृष्टिर्गतः ॥ उपमानादम
स्पृष्टलक भीमखड्ग लुप्ति ॥ भयवस्पृपमनाद्वस्पृलकस्य
क भागमः भाउ पति ख्यातिम पुगमविणस्तुलयस्पृष्टीत्वे उ
पलमः विश्लमः उपमनात् किं पलाकः ॥ ठववामिर्व ॥
क्रियायां क्रियाणां यामप्पदे ठविभूति ठववामिनः भूः पाकय
शुणति ॥ ख्याल्लेद्विमिः ॥ पदः भाउ पृष्टे डिख्यामः ॥
भवभस्पृरिभाल ॥ ठये पकारमिकारके डिद्वयमपिस्पृ
पुटङ्ढरः भागवस्पृते भवभस्पृष्टिवे पकारमिकारकेहि
यमसिमाललिनामृ ख्याल भाउ पभंगुस्पृगमः पकपुलविम्रा

प्राकृ पवने प्रत्पवने उडिवार्द्धि: ।

यः स्वक्रमपविक्षावो ॥ उत्कर्षं ॥ उत पुरुशास्तु प्वाकृस्प्राज उपा
णीयश्चश्रद्ध उपाक्षाय: णीयश्च णाय: प्रय: प्रपमाय: ॥ उपम
नोन्नव: ॥ प्वाकृस्प्राज संस्तव: ॥ अभिद्रव: ॥ सङ्ग्रयश्चभिश्र स
प्रय: ॥ प्रमूवेकल्पित ॥ सयाव: उद्भव: सद्भव: उद्भव: ॥
सिल्लीकुहेत्रपसने ॥ म्राय: नाय: ठव: पुरुद्रवाउ नीनिएत्ले
ज्ञ प्वाकृप्रः प्रनाय: ॥ कामूहावो ॥ विनाव: विन्नाव: मृत्पी
मृश्च विश्राव: अभिवा संस्रावः संस्रव: ॥ पद्मसुभव: ॥
प्रसूव: प्रभाव: प्रभाव: ॥ निर्यूहः ॥ पुत्राय: उन्नाय: ॥
निष्पव: ॥ निष्पयश्चक्रमक्लिनितिडि निष्कवणश्चविमथ: पठिप्र
वस्त्रालमू पठिलाव: ॥ उद्गिर: ॥ उद्गार: निगार: ॥ किर्
णह ॥ उत्किरेव उत्कार: निकर: णश्चमुविक्षेप: ॥ मृतृश्चपवने
सह ॥ वोक्षृक: प्वाकृ पूमकविमय श्रुवनेगनुविश्राव: पए
प्रमकश्चत्ल पुमकउडिकिं यमसांविश्राव: प्रश्राव: पक्षि
स: ॥ कर्क्षाप्रिस ॥ वकुष्टाकिणनेवोभृ: प्वाकृ सकुसश्चवामू
विश्रावपक्तिकल: माउ प्रश्राव: संश्राव: ॥ कुलक्रमे पालिर्गाय:
गहगुल्वठवनिपाउनाजभिकं कुहकुडनेकुल: कुहकुडनेकुहक:
पार्य: किं केना: कुहक: ॥ पणायशार्यमूविसंदराणनावायास्त ॥
पणीयश्च पणाय: नियकृनेनाप: तुहवहमिन उहव: मयं
संदर: पुणर: पुराय: प्वाकृपिक्रविमाणोचीठवेनेपृत्त सभा
गं: ॥ नेत्नस ॥ वडिल्वपविठक्रिकंनोवठाकृद्राकृस्प्राज
णाइक्र उपसनज्नमीद्ध: नीवाराणामसीजय: ॥ उत्क्षिप्रपर्ष: ॥
उत्क्षय: उच्छ्रय: ॥ परिकल्पवृ: ॥ वाप्वाकृस्प्राज पके पत
पुराय: पुराय: पक्षाव: पुप्लव: ॥ सपुहस्नाकृ ॥ हस्नाकृणि

Marginal and interlinear glosses:

पहुकराजुनामिह्नेन पुरुहडे ॥

उत्तमिलकृद्रकाल्पर्याकृ लिपा हड संक्रियाउ मक्रिकुउनिमहा: पुरियडश्रित पुणा: पुरपकि पक्षिनावाय: पुरा पुवाक्षिरि: सहुकरुराणाकर: प्वाकृ उत्त ह्याणपरिमि पुपि: ॥

प्वाकृपुणि नापुउहे पसमश्रुडि ।

निप्रव: उकु पुलय

कर्कोग्रिम उडिकपुत पहुप्ल विनकाठपुक्षि नहिपपस ।

पत्रपुसहि: प्रकाय: उडिमको नमूकडु पाकुपडकाय: उडिकुपुपकुरूपम पवकपठन: ।

[illegible]

[illegible] ॥ मरीचि [illegible]

[illegible] ॥ [illegible] मरीच [illegible]

[illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

भिन्न कुथः ॥ दशेचणिम्न ॥ चक्रपमनमृदशे गल्ल शाउ वणिम्नठचे
दनर्वणः चक्रपमनमृकिं मक्षउः ॥ ग्रन्थीप्यनिम्न ॥ ग्रन्थीदशे गल्ल
प्यनिम्न विक्षरप्यरः मिक्षरः उक्षवमृदशे गल्ल रामिमावनृमर्जनि
पाइदे यरकभुकाभ्युनिरक्तदे उमहापरं उक्षरः चक्षिजेपप्रवाउ प
पप्यरः ॥ शाक्रदेकमिमेप्यम्न ॥ शाकुदेगल्ल प्यनिः प्यक्षणदेकमि
मेल्लग्भरवामृं मूप्याल्लपूप्यत्रलिमवदिम्नरमूकिंमुके उदप्यानिउठं
नमृदे णदेकमिमेउनिकिं रप्याउः ॥ कंगल्लयेविमूथ ॥ नपदशेक
ल्लशाउ प्यनिम्न चयेदशेउयेन चयेप्यरः विप्यरः मूप्यरः जुण
रः मृचकः ॥ पनेहः ॥ पनेदशेः कगल्लहः शाउ प्यनिम्न पनिप्यः ॥
मभमिनल्लभूमंभयः ॥ नमयेरजयः शानुक्तं मङ्घः उक्षः रमभुयाम
कः ॥ उपाकृतमृमभ ॥ उपाकृतकः शाउ पुमयेजउपणल्लयपः उपप्रः
पुमयः पामुत्रमाधुणियणिदनिहः केवामृः रपिवद्दंगं मूपा पडिमुरु
भिन्न मभुः मनामृभिन्न मनः नगूंग्राउ नमीक्षउनिकदृदशेरापीदृ
क्षः प्रविहदेनन प्रविणं पयहदेननपयणं विदनिकदं विप्यः पयहक
दुरि ॥ दृरवक्षुमथः ॥ दवेपवेपथः ॥ दृरवक्षुदृमक्षनिवउ ॥
पाकेननिवउं पक्तिमंदुवप उक्षिमंनक्षिमं मक्षिणः मक्षिमं ॥ यामिवि
स्त्रिकृमिस्त्रिकृस्त्रुपिनम्नियल्लयनिहेरल ॥ यामक्तुः कृनिनिमः विप्रः पू
ग्रामृनयेनिनि क्षपकानमंभ्रमावल्ल मभ्रः भ्रपः वमुः यमृ ः यत्रः ॥
उपसन्नमः किः ॥ मउनिमभंमक्षनां पूमिः उपाणिः मनिः निणिः वि
णिः पउमवणाकः पउनिः ॥ कमहणिकगल्ल ॥ कमहपपमणि
कगल्लजमः किः शाउ णकूगवलकृउ एल्लंणीयउभिन्न एल्लाणिः म
गणिः ॥ भिक्षांजिः ॥ पकउरिकावकेउनिनिवउं णाउहवजिः शाउ
उणुमक्ष भिक्षां भवेहः नउिः सिनिः मुनिः ॥ माउिकउिग्रउिडउिकी

273

ण्यम् ॥ [illegible] दृतिः कमलिनिः [illegible]

[illegible] उपनयाऽन्ते [illegible] ॥ [illegible]

[illegible] ॥ क्रिः [illegible] पङ्क्तिः उपनीतिः [illegible] ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] क्रिया ॥ [illegible] ॥ [illegible] ॥ [illegible] ॥

[illegible] ॥ [illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥

[illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible]

मतवक्तृतिः पञ्चणा ॥ उषिमक्त्मिथ्याङ्गिवादिविक्रिकविज्ञातहृदयः ॥
महेषः स्मृतः । मिथश्च मङ्गा उपासना पद्मनावदना वदनाकरिज
तुष्टः करश्च दरश्च यातृना गुरुवर्षीधूते गङ्गा ॥ कीर्तिर्यशः क्रिया ॥
कीर्त्ता कीर्तिः मिथश्च ओघुः ॥ रेणाष्टांयांवाल ॥ यत्नांविषयं
णतेवाल स्मृतः ॥ केशहयश्रीगजाकरपरेश्रवकेशंकारभ ॥
पृष्ठयस्मुश्रीगजाकरपरेकुकरेपरेश्रवकेशः उकरभाषीति भुवा
डिका यस्कन्धिक विमञ्जिका विश्रमिकं ॥ मंस्तुयाभ ॥ वाल
स्मृत उद्धलपधचजिका ॥ पदयादलेष ॥ वाल चुमिका
मालिक ठवतः पुमनं मयनं मसूमेहृगः पेयः पार्थिक मदति
उक्तठमिकाभणरपमिं उपद्रवर्षीधूते उक्तठकिकाहृदपादि ॥
पुत्राणाष्टारयोरिद्धवा ॥ पनयः णते वाल स्मृत उद्धयमा भाषुः
हृदयच्च पत्रकंठं करिकंकरिं क्रियां नष्टं नतिवाकक्षीः पुत्रा
रभवा करिकः करीः क्रियाः नष्टः क्षीरकधम पिवंगालिकं
गालिं मल्लयं धार्मिकं धर्मिं धर्मा पक्रिम ॥ नाहूतहृम ॥ न
त्रिमापत्रपतिः स्मृत मालीवतिः मणभुतेउभृाणनिरुवामु ॥
पुष्प ॥ नमभकविषयठायेयुण स्मृत करलंपमुनं ॥ कर्णप्रणिकर
णयेन्न ॥ प्रगाढलानिठणतु ययोभा प्रगाढलठक्षी भालती
पिङ्गी पथल्ली उद्कंणीयते यशाभा उदकमती भांमदमतीभ्रा
ली ॥ इतिउभाल्पिथकमः ॥ ॥ त्रिंयध्मस्थलनक्कनक्कत
ध्यामल ॥ रंघन्नः पश्चापात्रिभ्रणतेः पिल स्मृत नक्कमध्कुरः
कण्ठवत पञ्चनक्क रंघक्कः भकरः उपमनाभयक्षुहं रंघम्न
लभ्नः वभ मक्षंकिं मलठः मलठः ॥ कर्ककमल्लेश्वकुनाफः ॥
नक्कपनक्कमाजेवतुभानेम्र रंघत मभ उद्द इत्वपपदमृणतेः पिलाठवतिमणठवकमलठ
वतिदः पिनहियतभापिनहियतेपिला ॥

[illegible]

भजायं दक्षिण: द्रष्टा दभागा पीड ॥ कुक्षिशूलं हा ॥ गुल्मीभूत गु
ल्मिडावलिंघने कृष्टा उदरवृद्धदुल शूलिडा शूद्र ॥ गुल्मीकृमिद
दन्तलिकाणक मन्त्रि मगणम दन्तदवदवमगद्भ ॥ पाड: परं: हा
मेणु गुल्मीभूत नडुदरविवभंधिह: कुणक्तिठिन्न दविडा मविडा
मविडा पदमलिक्रणदन्त किं दमिडा विष्ठिडा भविडा ॥ क्षतिवर्भ
स ॥ क्षिउणभूत काविह कुविह उदरववृश्चक्षि मांक्रि क्रि मिह्ना
क्रिष्ट्र गुल्मिडा भडिडा उडिडा उविहा पदीह उदरवकुगा मद्रु
मभिडा उद्र उभिहा ध्रह पविडा ॥ एंवक्षिविल ॥ क्रिभाउ लाविह्ना
मस्विह ॥ हक्कनादित्युपणंभूतविवा ॥ हक्कनादिदक्षिमुपणभूतवक
गडुपहवा मेलु गुल्मीवाभूत ह्रडिवा कृडिद्मालेपिदालिपिह ह
स्मनादि: किं पविह कुपणभूत किं वडिह पव: किं दविडा ॥ दवि
भविदखिवव्रिलवुडांम ॥ पभांयरहुमेल गुल्मीवाभूत उविहा
दविह भविह भविह कविह दमिहा वाडिह वमिहा लेक्रिहा ल
मिहा पवेडा पडिह मेल किं वहा ॥ मदनुगांयं वपक्षिभ्रम ॥
कृमेल गुल्मीवाभूत मक्रिह मविह गुडिह गुडिह वदनगां किं
पक्रिह पदयक्षिभ्र किं कविह रडिह ॥ ल्गुनुमाभनिल्भ ॥
ल्गुगांनमश्वापक्षिभ्र मविलंकृ गुल्मीवाभूत उल्कल्क गल्क
नंभु रभु रणलिकाद्रुल नमिहा ॥ नवक्रिडपि ॥ मंत्रमारलेनभू
ड पभूतयं: प्रवायव्य ॥ ठथ ॥ पथिवमंत्रमारलेभूत प्रहा
प ॥ मंपविहंवां ॥ मंवीय महाय पविवीय प्रविहाय ॥ यथिवा ॥
वगडिउवेहडिउविषणल्यपि पक्रमलपभूत पंवह विडह प
कह पुदह मगह ॥ वापः ॥ पमडुभूयपियक्रमलपिवाभूत भूल्ह

[illegible]

[illegible]

[illegible]

क. कि.
73

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

निमीयते ॥ एवं यस्मिन्नुक्तेथुक्तयं पठनं विनिर्माणम् । कृतिक्तृ ये क्त
मर्थाभावमात्र ॥ विभक्तिभावितक्तिलिङ्गवत् ॥ लिङ्गत्रयात्
एवं भावि स्वभावितक्तिः स्यात् यथः उभा श्रुवम् उक्तः पुंसः वचनव
…यदुक्त तिस्रन्तरस्य तद्भूतभावस्य प्रयोगे उदाहरणं यथा प्रातिपदिकार्थमात्रम्
एकः द्वौ बहवः ॥ प्रथमायास्तृत्क्रम ॥ प्रथमयाविभिन्नं भाषान्तरे उक्त
कर्मादिषु स्यात् ॥ संबोधनं कृत्वा कर्माख्यातपदार्थमात्रे प्रातिपदिकार्थ
॥ द्वितीयाद्याविभक्तयः कर्मादिषु स्युः यथा एव षष्ठीतिस्युः तत्र
तद्भावमेव प्रयुज्यते कर्मत्वया, षष्ठीप्रयाणे सीता भावभावगत्वं कर्मत्वं
एवं पूर्वा वैशेष्य भवति संबन्धिः षष्ठीस्युरिति षष्ठीभुवा, कर्तृकायात्
सिमानां कर्मकर्मणादयः कर्मत्वं भावे भावमेवत्वं भवति गतिके
भवेत्कर्मणि तु मनुष्यं वदति कर्मणीयानीयं भवत्ति भावभावेषु गतिक
रूभावेषु ऊष्ममात्रे तत्प्रभृति, क्रियाविशेषणानां कर्तृत्वं कर्मकर्तृत्व
मात्रम्, प्रयुज्यते भवभावेति संज्ञायाति तथा भवत्येवमर्थः
पूर्वोक्तद्वितीयापत्तद्या उक्तयुक्तं गुणिनमी भवतीत्या एविज्ञात्वयत्वेनापि
दर्शवनम् त्रिविधत्वं दर्शनेन स्वभावित्वस्य दृष्टं त्वक्तक्रियः
प्रकृतिः परिः समयानिकषायुक्तेनापि प्रकृतिकृतं परिः समया
निकषा प्रयुक्तोऽपि, प्रयुज्योऽर्थमनु ये पूर्वेनापि प्रयुज्यमानमाग्रतः
प्रयुज्ये भवत्कार्यं निमित्तहेतु ॥ प्रधानकर्मरूपनीयाः ॥
प्रादिषु भवति प्राप्तकालमेवं अंतः ॥ कर्मप्रवचनीयेषु ॥
प्रत्येकं द्वितीया स्यात् उदाहरणम् यथा विज्ञाय आङ्गिरसः ॥
पंचमीप्रयुक्तेषु कर्तृत्वम् ॥ पंचम्याभावे उक्तस्त्वभावं स्यात् कर
लक्षणीया गरीयस्त्वगति ॥ यःकर्तीभवत्ता ॥ कर्तरि तृतीया
स्यात् तस्मिन् इत्युक्तं प्रयुक्तम् पुष्पालिङ्गं तृतीयावस्था पुरुषात्मकः

लिङ्गत्रयात्स्वभावितक्तिः स्वभावलिङ्ग
वचनकर्त्रकमित्युक्तिविशेषणम्
लिङ्गत्रयात्मकवचनेन तदति वचन
प्रातिपदिकस्य स्वभावप्रयोगे
ति उदाहरणं यथा प्रातिपदिकम् ।
उदाहरणं वेदितव्यम् ।

प्रयुक्ति प्रकृतिः परिसमया प्रयुक्त
प्रकृति प्रतिपत्ति

का कौ.
१७

भायेल्याल्लिकः गेइल्गानृः यहेविदिउमजीयाम्हमृउ उभून
हुमय: ॥ मजीयाभदयेग ॥ भदङैयेग,कामभूल्लेखप्रभदङैल्ल
येगीमजीयाभूाउ भूणनाग्यिंभदउ भेल्भदागउ: पिउ पवं
भाकंभाठंभभंभइभगु: पभदयेगे उहकामभूल्लेपल्भदविपद
येगदिउङैदेगमजीयेहहवाहाणेनेन, ङ्लेनगदिउ: विषङ: ङुरः
दीनेवा ॥ देहङ ॥ देउवङमजीयाभूाउ विहुया यमः ॥ ङ
ङिउङ ॥ ङङिउङिनियमकृङुमृदुयि उभिंमजीयाभूाउ पङ्ल
उङुमव
कल: ॥ विमभल ॥ येनेपलेङुउ उइमजीयाभूाउ, एएठिमु
पभिमभू: ॥ यङ्कििङ्गेमउणायउवाउङंभमनभ ॥ यङ्कम
हुभिङ्ग यङ्केरमउ यङ्कपंणायउ उङ्गभूमनभंङुभूाउ भङ्
मनेमउजी विभूयगांमदउि मेङ्गयेमउभमक: मेङ्गयमउण
पखारलकभूयथुंमञउि परहलकङुनवथुंमङ्गुउि,
रयउ यइमनेपरभूङ्गभूंउइयंभङ्क, मयठाउ: भूयेगवाभाभवीव
भमवनेङभउजीवङुष्ठा मवमुायमपउ वाभाभवीरभमनेकिं म
वमउंमपाउ ॥ भमदेङ्ग ॥ मेङ्गयभमदयउि, हेणङैमभ्रयाङमां
यंभूउिकेप: मवमुायङथुउि रहुउि भूभ्रयाउि यंभूउिकेप:किंठ
दभीहुउि मेनाभरेङ्गकीमिउि ॥ उमहेमउजीयाभू ॥ भ्रयाय
मन दिउयेगपि गेहेदिउभ ॥ कृपः भूयेगपि ॥ भिङ्गयेक
लमउउप: ॥ एनेङ्ग भुठयलयउमउि: ॥ उमङल्लठदवामिः ॥
ठयवामिनल्लउिभ्रइल्येविदिउमुमङ: भूहयभूमउाल्लउजीभूाउ
पाकाय पङये पमनायवाभूलाउि पङुमिहङ: ॥ नमः भ्रमिङ्गा
दभ्रणलंवभभूगमउजी ॥ लउेदेगमउजीभूाउ दम्यनभः
उपभमविठङ: कामकविठङिवलीयभी,नागयल्नम भूद,

[illegible] ॥ [illegible] कर्मणि द्वितीया
सप्तम्या [illegible] ॥ [illegible] सप्तम्यां
[illegible] सप्तम्यां किं [illegible]
[illegible] ॥ कर्तृकर्मणि [illegible] ॥ [illegible]
[illegible] कर्मणि द्वितीया [illegible] सप्तम्यां [illegible]
[illegible] किं [illegible] किं
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] अपादानसंज्ञं स्यात् [illegible] अपादाने पञ्चमी [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] अपादानसंज्ञं स्यात् [illegible]
[illegible] ॥
[illegible] पञ्चमी [illegible]
[illegible] ॥
[illegible] ॥ [illegible] पञ्चमी ॥ [illegible]
[illegible] पञ्चमी स्यात् [illegible] कर्मप्रवचनीय [illegible]
[illegible] ॥ [illegible]
[illegible] द्वितीया तृतीया पञ्चम्यौ [illegible] ॥ [illegible]
[illegible] विना नाना ॥ [illegible] ॥ [illegible]
[illegible] पञ्चमी स्यात् [illegible]

क० का०
७०

द्विवसन्तु । ठउं मण्डि: ऋउं मकि: ठउंयेगं द्वितीयायां षीथुउ ठमन्उं कः मह
उ । परट्टीउ । ठित्र: विलक्ष्मीवा ॥ गुल्मावामित्रि दिउं वक्त द्वितीयायां पञ्च
म्यांवामु । पलमतिमपलद्भुउ । थूयायामक्रमेन प्रतिमपलद्दीवा ॥ भ्रा
भ्रातियेगं षष्ठी ॥ ठमथू भ्रामी मिंइथू ग्वं गुरि: मिथू: यिउ: भ: गण्डिचद
षष्ठी दिउ रुयेग ॥ दिउ मकृरुयेग मति येदिउ भन्नान्द षष्ठी थूउ । द्वितीयाय
भ्रा पत्रथू दिउं व्वमति ॥ द्वितीयेन ॥ गमरुयांउ नयेग द्वितीयाथूउ ।
उउरुल्ल गूमंवमति मक्तिल्लन षष्ठूपीथूउ उउरुल्लगूमथू ॥ मन्त्रग
कमलि ॥ मन्त्रगागं कमलि षष्ठी थूउ । यिउ: मन्त्राउ माउन्नायति ॥
करिउं: शुतियह्न ॥ पञ्चकमलि षष्ठी थूउ । पुतियह्न गन्द गुम्मु उरिष्ट्नगं थ
तियह्नं तपिण्डकथू पञ्चकृठउ ॥ हिंमाफनामन्नुर: ॥ स्तुवदि उभांगिमा
गांकमलि षष्ठी थूउ । मियथूफलति रेग: मरि भुमतिउम: । पञ्चरोकिं
मोरं न्नुवयति पञ्चवि मञ्जाथूतिति वामूम । मिंयमन्नापयति उन्नाफ्रेदेगं द्वि
तीयाषष्ठी वक्तउ उन्नेमिंइल्ल मिंइथू वा मदम: ममान: मम: ॥ कदकम
लिः त्रितिवि इम । ॥ गन्नुरुयांउ थूपञ्चमानेकउविकमलि मषष्ठी थूउ ठवउ:
पुमिका ठवउ: मायिक वण्णथूठउ कुवनथू वक्तिउा ॥ नविन्नुाक्षिष्ठ पषथू
पञ्चमानेषुक कृतकमलि: षष्ठी नथूउ । विम्भु फन्तु म न्न मक्रथू कनमामए:
न्त्रिणमक्तगम्भ्रामित्रुथू याद्रकमे फकाल । वन्तु मञ्जापलकावाद्विष:
मन्नुरुण्णदउ: ठवेऊ स्राणिकनल्लाकृवतुन्निउस्त्रन उन्नामीययकावल्ल
षष्ठीकउविवामठउा पक म्भिंन्नि ठयथूमुमहंग्निरिं उकमलि ॥ यन्तुणन
भुमणिकनल्लम । ॥ यम्भितूवतिभ्रु नेउमणिकनल्लमंलुथूउा पणिकनल्ल
मपुमी कण्णभु पदकृ मेउ । निमितु क्रमयेगं मपुमीवाथूा । मक्तलि
द्विपिंदतिमन्नुयेदनिजक्लवन्ना । कमैम थूममरीदतिमीम्रिषथूल कंदउ:
मवनांभ्रं दिउकावल्ल निमितुथू येलन मक्र येगं मवावि ठजयउथूउ कंदिउ
वमति किं निमितु मिहाक्ति ॥ कलकवयें: मपुमी ॥ काले ठवमगमथ

निलुउ क्रियया नि लुउ क्रियाकषगंठय: ।

[illegible]

अमीयं वस्तु:

षष्ठ्यन्तात्लुक् ॥ षष्ठीकारणात् षष्ठीतत्पुरुषाद्विकर्तीनांल्लकाः सन्तु । उप
प्रत्ययेति प्रतिनीति उपमकु उपवश याव[illegible]वणाल्लेसमस्तु याव
[illegible] नामाल्[illegible]श्रुतिमासमस्तु षष्ठीतत्पुरुषसम
भासः पत्नः माकः मात्कश्रुति [illegible]श्रुति प्रपपारिवदिच[illegible]वाप
[illegible] प्रपमन्तु प्रपमन्तेचा तपः परिमन्तु परिमन्तेः वदि[illegible]
वदि[illegible]मासु । श्राम्रं श्राम्रमासु । [illegible]विष्टेः [illegible] [illegible] ।
संभारः प्रवालं प्रवालेहः मिथतक्रि: पतिः संभाष्टे प्रहर्कां
समृति प्रत्यक्षीवीक्षयांस माकल्पेन[illegible]मिस्तु वीक्ष प्रस्वं श्रुतिवं
वावीक्षयां [illegible] प्रतपिनं श्रुतिपिनं वा पारिभद्दे[illegible]षसूत्रेण था
[illegible]निणीरभमुत्र । भद्दे[illegible]कप्तः पिमक्षीः [illegible]यामर्कं
वंसून षष्ठीतत्पुरुष समासः वंसू: [illegible] [illegible]
[illegible]करम्[illegible] । षष्ठीतत्पुरुष[illegible]कर: समासात्तु
[illegible]श्रुतिसमस्त । उपाविपासमस । सरस । विपास । [illegible] । [illegible] । उपान[illegible] ।
[illegible] । [illegible] । [illegible] । [illegible] । विम । [illegible] । [illegible] । [illegible] । [illegible] । उप[illegible] ।
[illegible] । कियत । [illegible]: समस्त[illegible]: ॥ [illegible]
[illegible] ॥ उपकुम्भ[illegible] ॥ [illegible]
[illegible]उपकुम्भ[illegible]स्ते [illegible] [illegible] समस्त [illegible] [illegible]
[illegible]समासात्तु प्रकरः उपरपां षष्ठ्यन्त[illegible] । [illegible] उपम[illegible] उपम
[illegible] प्रतिपिनं प्रतिपिति इति षष्ठीतत्पुरुषसमासः ॥ ॥
[illegible]: ॥ [illegible]द्वितीया[illegible]
[illegible] समस्तुसमासे[illegible]: ॥ [illegible]समासे द्वितीया
[illegible]समस्तु [illegible]
[illegible]: [illegible]समासे[illegible]: ॥ [illegible] ॥
[illegible]समासे[illegible]: [illegible] । [illegible]:

वालुभद्राणं

[illegible]
[illegible]

माचार्यस्त्रिइः मतिस्त्रिइः ॥ शृङ्गातुसृयश्रुठेः ॥ शृङ्गातुमृ
सठेइगणपद्दस्कं उज्ञमामे विठक्रिलेयन्तडेश्राउ(द्विवंगाइः दूगाइः
मकुलयापनुः मकुलापनुः ग्रुपाय मन ग्रुपमन वकेहेठ
यं वकठयं विद्वधः मुजः विद्रुमजः मठेतिडि पुगयद्वमनात्रे
दमद्वम(मयांठरः मद्धरः पितृतितिमूलः पितृमिमूलः क्रमि
द्वितीयातुंप्रवयमेननाम्राममभूडे शुखुलीविकं शुखुलीविकः
ग्रुपत्रलीविकः प्रतिङ्गुःपङ्गुं प्रतिपङ्गुः मइलेशाङति मह
भूइयतिद्गिमाकुतुमद्धलेयः क्रमिद्वितीयाहठयेयिउद्मनमङभू
डे श्रयं नेत्रे श्रयं नेत्रे मामिकुकं मामिकुकं ङवेन तिरमभामेवि
ठक्रिलेयत्र ॥ वागज्ञाविय ॥ पद्मतुन्नाणिकरल्लविल्लुयःक
मणरयः ॥ यदिकाणिकरल्लउङरयठयरे प्रवयठंममभूडे मक
मणरयमंल्लुः ममामेल्लुयः ॥ कमणरयमंल्लुडुपं पद्धवेविर्ठय
डे ॥ पम्मिद्मभामेमंठुप्रनलीकेपणणंउन्नाणिकरल्लेमूलि हि
,प्रसरनमपवुउरयठेपंवद्धवःक्रियडे मडग्नामोवमरिका मडु
वमरिका पद्मभवमरिक भामकवमरिक, उडरपमभ्रामीड
मिदन मेयमडुपुकङभा मप्ररन्न्फेकिं मडुप्ररली मडुश्रिया
ग्रुमिगृहन्नुउ(पियामरेठुकन्नामीमठगामठगाममा मभि
वामदिउकजुवालाप्राठक्रिवामना ॥ श्रवेमनवियदयः श्र
श्रवेनभ्रामनवियदयः श्राउ(मराद्वः रभूउद्धमनयल्लेयः ङउि
लेयः मभूगलः ॥ प्रुकरभदङःकदमुन्नाणिकरल्लयमे ॥
पम्मिदरेभदत्र(मद्धभ्राङकदम(मदंत्रामोदवेभदमयः ॥
ककी. मठुप्रवेद्विगुविल्लुयः ॥ मठुप्रवःममामेद्विगुमंल्लुः ...यः
१३ उद्विउजपुमद्ध उङरपठेममादरेमाठियेययाभिभूडे पङ्गुमद
पालेपुमंमूडङतिविमूडे ॥ पवमाठेराल्लिभूडे ॥ मंतुङाफू

ञ्लिप्सृते पञ्चभीसधुश्वैः द्विगोविधक्रीत्रेयमनन्तु उमृद्विगो+
र्लगनपठेऽत्रिउञ्जुवल्लेपः पञ्चकपालः पुरोडाशः समयठेकिम्
द्वयोर्द्विरयोरपठं द्विमिद्रिः उजुरपरि पञ्चगावोधनं यस्येदं द्विगोर
उ ॥ उत्तरपदावृत्तौ ॥ कप्रत्ययो द्विगुद्वन्द्वयोरुत्तरपदमकः स्यात् ॥
समाहारद्विगोर्नपुंसकलिङ्गमनसुजा ॥ समाहारे द्विगोर्नपुंसकं स्यात्
दीर्घांसकानां पञ्चानां स्यात् वामसैन्यरक्षायां उत्तरपदनकुः पञ्चानां
गवां समाहारः पञ्चगवम् सगोमकुरुत्तरपदमेव स्यात् पञ्चानां समः उत्तरपदी
दिः पञ्चगवधनः समाहारे पञ्चानां गवां समाहार इति वाक्ये पुनर्व
समासः ॥ अकारान्तो द्विगुः ॥ द्विगुः समाहारे नपुंसकं स्यात् पञ्च
गवं पञ्चगवमिति द्विगुः स्त्रियां स्यात् पात्रादिवर्जं त्रिरात्रादिवर्जं
त्रिलोकी द्विगोरी पञ्चपूली त्रिपदं द्विपदी चतुष्पथ
लेपन्न पञ्चपूली पञ्चपूलं पञ्चखट्वीति समाहारद्विगोरनदन्त
वाचित्वमेव प्रातिपदिकमिति पञ्चपात्रं त्रिभुवनं चतुर्युगं त्रिशं त्रिश
कुरं चतुष्कं पञ्चराज्यं पञ्चभारं पञ्चगवं पञ्चगवम् त्रिगवादीनि
स्युः समस्तयामिति कुलिमवल्लाकारः समाहारद्विगौ पञ्चानां कु
लीनां समाहारः पञ्चकुलम् त्रिणां कुलीनां त्रिकुलम् ॥
यदः अवैकद्रमसङ्क्षेपत्वञ्जपादेः तद्रूपदत्तः समासः पुंसिवद्भवेत्
षडरादिः मधरादिः मधुरादिः सकर्मादिः सकर्मादिः प्रभवादिः पञ्च
म्ः द्विमितराद्रयः द्विराद्रिः पञ्चराद्रिः रात्रयः अपिदृष्ट्यमुत्तरपदमेव स्यात्
मध्रक्षामोगतः मदरात्रः सर्वरात्रः पञ्चमादः उत्तमादः संकम
पः सुप्रियन्तूः पञ्चेहः पञ्चेरङ्गं सदगतः पञ्चदिनः समाप्ता । सूत्र
प्रिउविदधर्मैकिमः पञ्चानां राजीनां नित्यं गम्भमायायां स्यात्
उत्तरिउराज किंराज किंसखे । सर्वसखेऽपि उत्तरपदस्य समाप्तेः ।

प्रवाद्धः मण्डूकः पथवाद्धः आयाकः नमस्कृतः समादरे हूदः प
ण्डदः सम्पादः पृष्ठगृह पृष्ठसमितिनाहृत्यमदउति । पदकृत्यमप्यंसक
स्तु । पृष्ठसदः पृष्ठदम् । नर्वीविद्विगीरम् । पक्वावं पक्वावदिथ्यः ॥
मगाश्च ॥ पतंनाविरतावं । पापरवा । पापरपचं पतापारं पमप
तापारी ॥ उपपदमतिङ् ॥ गतिः कारकोपपदात्कृत्समासः प्रा
क् कुम्भकारः गौडः ॥ अमैवाव्ययेन ॥ अमैव तुल्यविधानमुप
पदं अमन्ताव्ययेन सह समस्यते । कालसमयवेलासु तुमुन् कालः प
रमाकिं मूलकमंकरोति ॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ तृतीयाप्रभृतीनि
उपपदान्यमैवाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भु
ङ्क्ते मूलकोपदंशं उपदंशं मूलकेनोपदंशं वा उच्चैःकारं करोति उच्चैः
कारं उच्चैःकारमाचष्टे ॥ क्त्वा च ॥ तृतीयाप्रभृतीन्युपपदानि क्त्वा
न्तेन सह वा समस्यन्ते । अर्धं पिप्पल्याः अर्धपिप्पली अर्धं नपुंसकम् अर्धं पृथुः
समांशवाचिना अर्धशब्देन सह एकदेशिना नित्यं समासः । ग्रामार्धं
ग्रामार्धमेतदिति वा चार्धं नपुंसकं नित्यम् । मध्याह्नः प्रवाहः
कस्मिन्या द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् पूर्वार्धं
सद्वितीयाम्बरम् भिक्षाद्वितीयं भिक्षायाः द्वितीयं वा द्वितीयभिक्षा । द्वितीयं भि
क्षा । तृतीयं भिक्षायाः तृतीयभिक्षा । चतुर्थं भिक्षायाः चतुर्थभिक्षा । तुर्यभिक्षा
तुर्यं भिक्षायाः । प्राप्तापन्ने च द्वितीयया । प्राप्तो जीविकां प्राप्तजीविकः
आपन्नजीविकः आपन्नो जीविकां । द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
इत्यादि ॥ कोः कत् ॥ कुत्सितमश्वः कदश्वः तत्पुरुषेऽचि कुत्सितोऽन्नं
कु. आयतः कदश्वः कदन्नं कदध्वः । रथवदयोश्च तृणे जातौ कद्रथः क
कौ. द्वदः कत्तृणः ॥ का पथ्यक्षयोः ॥ ईषदर्थे च । कापथं काक्षः ईषदुष्णं
१३ कोष्णं कवोष्णं कदुष्णं । कवं चोष्णे । कापुरुषः ॥ पुरुषे ॥ कोः का

शृगाल जम्बुकः क्रोष्टा ॥ प्रतिमेदुविकाशया ॥ कोः कर्णशृगाल कश्यपः
जम्बुकमेवा उष्ट्र मर्कटे कोः कपि कपिकचापानुः रोमन्थोयं विरो : कपि कपि
मृग कपिमृग ॥ याकरोपीतजोष्ट्रोमर्कटमिड । मियांनत्यर्थीकरणं
रोक्षमिह मृगोस्तः उत्तमपदे रेवति मिहः रोहिलिमहः उष्ट्रक पीका भा
लानां मिहकुलकविशु उष्ट्रक किल्विषभ उष्ट्रकमिहमा उष्टीकयाकुलं
उष्टीककुलनम भालंविकत्रि मालकाशिलीकटा उत्तमुमधुपकल्पयं
लुल्पमुक्तवतोद्भमदकउष्ट्रपरोक्षीभूतयायभुनाकेकमनस्तमृमेवामूः कनि
दृगा सृङ्गालिडमेदाति ॥ मुखमूपीडता ॥ कपिमूत्रमूषीक्षमाउ
मूमुभकपालेशुभंमृतः परोक्षमः मुष्णाकपालः ॥ विश्वमूधमर्
गेः ॥ विश्वावसुः विश्वाराणं नरम विश्वानरः मिहमधो विश्वामिहः
मर्गेःकरोडुंग्रे ॥ मरोक्षप्रकृतीकडिभ ॥ उडितमृगमधः ॥ मृदय
मृगशृणनेवमृतीदि ॥ मिश्राउंयमिपत्रुउयमिवामूचुउउरपि
उत्तराम्युपदमूजेवमृतीदिः ॥ यत्रममामेव्रुपमेमाउंयमियावमृति
पदमिरमूमाररमृपदमूजेवाकृभदिममनृतेमवमृतीदिभामाउ म
मुद्राविमेधनमृमवराग्रः मगुयामवमृतीदोप्रवरिर्पाउंवामृः उत्तुउ
त्रि सिलेपेभूपुत्रुभिक्षमुद्रालेपेरेभृतु उरमिलेभातियभृ मउरमिले
मा पुढतोपानरेठकं ॥ मउत्तउपामरेडमः करोकलयभृ मकतेका
लः मउरदधेभाउंगयमृतउमउरमभाउकंपनम मर्वत्रुउयमृ ममवत्रुउः
त्रेकागोत्रुजेयमृमत्रित्रुउः परिमथेःमभामेपृकूलाउकंवामृम पत्रुः
श्रियिमृ मपषित्रियः णवंमषित्रियः ॥ पंयत्रुपिउपंकूउपलप्रगहणि
मुश्रियां उन्नाणिकरल ॥ उडदिउणयिउपंकूमाश्रीपंयउ माग उन्नाणि
करलंभीलिकउत्तमपमेपरेनउप्रगहणा गोश्रियेमपमलनमृडिउनु
तुरामरपमृ मृमः मित्रागावेयमृभमिड्गुः क्रमपकदः पउत्री
कादयमृमवाउमृकदः वाउमृमकमृदिश्रियांपउत्रीडिकुमम ।कमि

इथंशुक्लकिम (उमाठद्देदरः पञ्चदशकिमा (वमे कृठरः पुरस्तंगु पुरली
श्रद्धयपूभाग्यगुक्रशीदेवध्याघृः कल्याणीपञ्चमीयाभां डाकल्याणी
पञ्चमा गद्दयः श्रीधूमालीयमृ मश्रीधूमालः प्रथंकल्याणीधियडहा
ति धुंवक्लवनिखेठः पपूद्दयपञ्चखणमप्ररालीश्रद्धयाजुगादेवधृडे पश्चदि
गद्दयः श्रूणमम (प्रमयपञ्चमीगद्दिगधिपूविधेवुडिभाधिपूणमम (पद्दह
डुगमीठप्रगुद्वक्रशीदेः कथ्याघृः कल्याणपञ्चमीकः पक्षः वक्रकम
कः पूमाढः ॥ मल्लपुरालीकैपणभुर ॥ मंल्लकुडः पुरालपूद्दयाजु
कैपणञ्च ठधिडरंभूः धंवत्रधृः पुवतिमिडे मडुगठदः पञ्चमीठदः पा
मिकाठदः ॥ एडिब्रजक्रलीठादः मद्दियेवक्रशीदेह्लिधृडे पञ्चघ्न
गमिल्लेपूः श्रमीपेठमानां येडेउपठमाः ॥ डेविंमडेगधि ॥ यिंमडेधि
मठपूलेयः भाग (दगवडू पधिमठ्डमठज्ञवप्राञ्चग्रादेञ्च पुमत्रवं
माः पुडरद्दिमाः पणिकमञ्चरिमाः वाञधिमञ्जयावक्रशीदिविधृड
ञ्चवा इयेवा ञ्चिरः पञ्चवा पञ्च पञ्चमाः ॥ विदिक्रथा ॥ पइमभा
मेविविगद्दपठज्ञः मवक्रशीदिः भाड (मवमेश्रवडिभाइँधवकृपः
ठक्रिलपुवाउपेरजुगालमिद्दज्ञः प्रवंधवठक्रिघ्रडदपिठवडि म
वश्रियः मवभगेल्लडहादि कदहृडिदरेवक्रशीददिलिधृडे पुकरे
मदङः कादुडहद्दकदगृदश्रुपुवपठभाद्र कदहृडिदरेवक्रशीदे,
परयाञ्च ठहेञ्चठहेञ्चयहु पूठडु ठकृगठदि डिमुगुश्रद्धजीतिमिडि डञ्चजुगाठ
श्रयडं पुवपठभाञ्चरमीदेवावज्ञहृः मञ्चीमञ्चि मञ्चामञ्चि कमेधृके
मधृगठीडंठंशूठडं कमाकेमि ॥ उपक्रमेड्रमाधाहृः ॥ श्रडरेटि
यमिमश्रद्धये उपक्राडंमधाहृः पवागमः गादगादवि गाक्रगाद
यि पश्चरेकिं पभूमि लिरेमपुवडडेल्लपकाक्रदश्रमः पृहेलमद
क. मधृः ॥ वक्रशीदेमज्ञाल्लेः ॥ पमधाहृः । गेगमज्ञाः पञ्चमी
को. कमः शुभिगजुवयेरथीधृडे शुमज्ञाः शुभ्रकः डहादि ॥ ञ्चिद्दिहंप्र
१८

पृः ॥ द्विप्रहः त्रिप्रहः नेकूरुयपदम्भफलभा। मगीस्नायायां
कुभगानेङ्गारश्यः पथृनेङः पमे मगनेङपः पथृनेङरः पद्मा
ठेलनाठलीग्रनश्वद्यनाङ्गन्विपहुन्ते पद्मनाठायपृमपद्मनाठः
कूलनाठयपृमकूलपाठः लीद्रनाङ्गिः लीद्रनाङ्गः वद्मनाङ्गिति
वस्कनमिनाकरह्वाह्वद्यनाङः पङ्कमिकायाः मंस्लुयां नमकानु
लाउ। भदनमः कुम्भीनमः गेनमः उदन मुलनामिकः पिनाप
गहुंनामिकायानम। पमे प्रम। पिरनम्नः पिरनमः पिरम्नःप
नमः उपमजाप्र मुनमः मनमः वेःपुः विग्नुविगउनामिकः
निहमभिम। मलमेणयेत्रकुंमहः पथृलः मथृलः मथृलः पमे
णः हमेणः षमेणः विरंमुदश्राउ। महमेणः मुलमेणः णम
मविम।केवनाउ।मनमृणमा णमः मुमंहांलनेल्लः मलः मुग
उलनकः मंलः मंदउलनकः मलेल्लाग्रिठधा मलमः मलल
कः कमलः कमुलः णवषेहमाम। पिनाक णग्रा वामंलयां षध
णग्रा षधणनः लयाउमृगमृतिः ग्रेचाकनेयेउग्रियलेपः मलतिः
पुपलतिः लक्ष्मीलतिः गरुमुंदद्रउयमथठिहः उद्गत्रिः प्रति
गत्रिः मगत्रिः मरठिगत्रिः मखुवमृपिमहमृउ हनत्रिः उप
भानाम्र पद्मनात्रिः मल्दापायांम पटउगत्रिकेलनं मल्दउप
दयेयंगत्रमद्यः पादमृगमृलेपेदमृगत्रिहउयभानेहः पृप
पाउ। पदमृगत्रिहः किंदश्रिपादः दमीपादः मकूलपादः म
हमपुवमृम द्विपाउ।त्रिपाउ।मपाउ। वयाभिदउमृदउ।महम
प्रवमृव पचेदनामिहमृउः दमृडः मदुउायमृमषेदना।
षेदउा मदना। मदउा त्रिउमदवउ ग्रीलिकदगदनियमृहउलेयं
नियाहउ पहमिकउगदः महमहमे भिग्रुभिश्रयेः मेठांहमयं

यस्मूढिहृतमैसनियाहृतै वहृत। सिंहं दहृत। मङ्गः उरः खहृ
डिहः कथ। वहुशीदावैवं वुद्धिस्कः खमान। वृत्तहृन। गोः
पयः लक्ष्मीर्विष्टिकवमनातुः उरः खहृड्यिपश्त्वे अधियः ख
मातृस्मृमध्यियथंस्कः प्रवंशियात्रहुकः श्रियपीकः मपयस्कः
मलक्ष्मीकः वैदवहृश्यमान। वहृवहृन। द्विगौः वहृपयाः
वहुलक्ष्मीः भाद्रमद्रणदिवैश्वै ऊडीभाडायस्र मऊडीभाडः
मधीभाडः पूर्वस्य गानीभाद्मकः पश्चऊभभाभातुग्रुवहुशीदिः
कथावा डंदणनाह्मवरणहृभाद्मकम। पाद्मनः भवेत्पाः वै
यशः वहृद्यपभी पुरुषः श्रियहृयभी नारीडहूः भ्राद्म वेहृवर
हताङिः भुताङिः स्त्रियामिष्टपिकरे विदिड्युल्लक्ष्मीडहूनेष्टि
यैसिडिहस्यैत्तामिभडीः भस्रीक डहरौपृष्टिकविदिङस्थी
यिरकपीतिड्यूतुराड। वहुमीयभीहृतेमवैपसैपुहृवहुशीदा
विडिवादिडपुत्रीत्रिभुष्ठवनियाडः पुढिडप्रिः पस्राडिडिवाप्र
स्वरः प्रत्ययः ॥ इतिवहुशीदिः ॥ अथपरपदप्रयोगे
द्वन्द्वः ॥ द्वन्द्वः समस्तयैनाभिरहृवांयाधिपैठवैडा ॥ द्रव्येभे
वहूनांवानाभायः समस्तयः मद्वन्द्वाः समासः भूतञ। भरस
भाद्रवैडवैडवयैनमैकः यद्यभद्रवरणहृंभभमादवः पुहृङ
वैडवयैनः द्रव्याणिक्रदमेवाहृयांसहृणकुतांछलानीतांस
समाद्रवायद्वन्द्वः ॥ पन्नुस्रवडवंड्ड्रवभ। ॥ द्रव्यद्वन्द्व
भूवडवंप्रवंस्रयैहृम। ॥ द्वन्द्वकडुम। ॥ द्वन्द्वसमासमूसमा
कु॰ दावैवंसकंभूता कृतैयवरस्त्रैपडकुरयवलम। माद्मद्वि
कौ कपालविकम। गाण्डुं प्रकालिमं वद्रामलकम। भुरामस्त्रि
७५ डरगृदत्रुल्लब्बरमूप्रवनियाडः ऊमकामम। सिद्धवैसिंन्नु

सैषुन्नमसोऽसमयस्तयोऽन्तःकि ॥ इति द्वन्द्वः ॥ ऋक्पूरप्पथामक
रः समासान्तः, अनक्षः पुंसि तत्पुरुषलिङ्गवास्ति अर्धर्चः अ
र्धर्चम्। द्विरुत्तरपदं समासादरपूरम्। अक्षं अधिपुरं ली
पञ्चविंशदपूरम् अर्धमासं लभते अब्लकारप्रलोपः एवं पञ्चाम्
सपुरम्। पदमिमाल्ये पथरः पदका। साम वक्षमिवेदः पथर
वहन्कं अक्षं विष्णुपुरम्। जीवदुर्लिकस्। विमलापं सरः द्वत्रय
समनेष्टिपर्यन्तं। द्विगस्त्रुयपयम्भिम्भुङ्। द्वीपं अन्तरीपं पृतीपं स
मीपं समुद्रा सदसयः सन्निष्प्रयः समुद्यं पृष्ठवर्षा
हं सामलोमासात्मसः। प्रतिसामं अनुसामं अवसामं एवं प्रतिलो
मसिद्धादि सङ्ख्यायामसीतिर्वेदः पञ्चरात्रं सप्तगारथम्। अचतुर
विचतुर सुचतुर स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्
वष्ठीव पदष्ठीव नक्तंदिव रात्रिंदिव अहर्दिव सरजस निःश्रेयस पुरुषायुष
द्व्यायुष त्र्यायुष ऋग्यजुष जातोक्ष महोक्ष वृद्धोक्ष उपशुन गोष्ठश्वाः एते स
मासान्ता निपात्यन्ते। अविद्यमानाः चत्वारो यस्य सोऽचतुरः विचतुरः सु
चतुरः स्त्रीपुंसादयस्तत्कर्मद्वन्द्वः स्त्रीपुंसावित्यादि सह रजसा वर्त्त
ते सरजसम्। निश्चितं श्रेयो निःश्रेयसम्। ऋक्सामयजूंषि पुरु
षस्यायुः पुरुषायुषम्। द्व्यायुषं त्र्यायुषम्। ऋग्यजुषम् जातोक्षः महोक्षः वृ
द्धोक्षः सदृशः शुनः समीपं उपशुनम्। गोष्ठे श्वा गोष्ठश्वः ब्रह्महस्ति
पल्येभ्यो वर्चसः ब्रह्मवर्चसमित्यादि अवसमन्धेभ्यस्तमसः अव
तमसमित्यादि श्वसोवसीयःश्रेयसः श्वःश्रेयसमित्यादि उपसर्गाद
ध्वनः प्रगतोऽध्वानं प्राध्वो रथः पथः समासान्तविधिर्नित्यः ल
क्ष्मीपथं वहुपथं देवसरसं विमलसरसं सवनसमदकराणुड्
द्विद्दसमादरे वाक्यं श्रीमूलं वागदमकं वाग्निपुरुषम्। कङ्कालसकं
समादरे कियान्नकुमः ॥ इति समासान्तविधिः ॥

इति समासप्रक्रमः ॥

कृ॰
कौ॰
७८

ति उपगोरपत्यमिति विग्रहे ॥ तस्यापत्यं ॥ षष्ठ्यन्तात्पत्येऽर्थे वाण्स्यात् ॥
वक्ष्यमाणश्च ॥ एकारान्तवतुप्रत्ययपञ्चमिश्रसमूहवद्धिः स्यात् ॥ उपगुस्तु
भाषायां ॥ एवादिमः स्यादि अपवादः पक्षे उपगुपत्यं उपगोरपत्यमिति
समासवाक्ये सङ्ख्यंश्चतुष्प्रत्ययायाभावस्तस्मिन्कार्यमूलमात्रमेवास्य : ऋषेरप
त्यपत्यं द्विभावरः आप्नुवरः सभायाभावरपत्यं भाष्यवरः तत्कर्तुभावरि
विशेषाद्दिदुष्टद्धत्रऽपत्यं तद्भावुर्वः कश्यपाः कश्यपादिमः कश्यपाप
त्यं कश्यपस्याभक्त्वा ॥ स्त्रीभिः ॥ एतद्गत्यपत्यवान्‌ । शुद्धयः स्मृ
त। पौत्रस्यापत्यमद्धटे गानस्यापत्यं गार्ग्यः वाह्नः पक्षे समासवाक्ये ॥ प
त्यश्च ॥ धृत्यपत्यं भ्रात्यपत्यः वाद्यमद्धः ॥ भाष्यस्त्वजा ॥ उत्सा
दित्वर्थे पौत्रेऽ भ्रात्यपत्यः मनः भ्रात्यपत्यं लोकः स्त्रियस्त्रिसंयवज्ञ
सः सैन्धवः शुक्रिमः शुक्रियः भवमहत्त्वेऽगमस्यायां यः स्वागमस्य
मेरोरपत्यं भवसः गविष्ठस्य भावमः भावयः स्वयंगपत्यमेवगविष्ठस्य
गविष्ठसिमृत भालयः गानवन्नवणभक्ति स्त्राप्यपात्रमधिरूहभक्तलवि
वृत्तमनानिवनाः ॥ स्त्रीभिः पञ्चमिश्रगमः ॥ पञ्चमाहृत्ययानि
पाश्वत्रसमूहवदिकस्मात्‌ सुयस्त्रपत्यवद्विशाभमः स्मात्‌ स्त्राप्यपत्यपत्यं
वैयाघ्रपद्यः ॥ कुत्समिराघनमृतः ॥ कुत्समिनगमपत्यवाश्यपत्य
तः उनमान्नवऽस्त्वमृत भवभियांतनरेसूर कृशाप्यपत्यं कौशल्यपत्यः
कौशल्यमहा कौशल्यनाः नत्तमिल्पी कौशल्यनी नरमिर्दर्शनमृत नाडय
नः नाडयनो नाडयनाः स्वमृत्याउनलमिश्मदगति स्वत्वभू मुयनस्मा
उमापत्यनवमृत गार्ग्यमपत्यं गार्ग्यायणः वास्तुयनः कुशस्यत्व
नत्सवनलिश्रनदि उत्साहकुत्समयः ॥ शुभ्रादिभ्यश्च ॥ शुभ्रयाद
हेतःकिरिस्त्रापत्येऽवानयतः स्यात्‌ शुभ्रस्यापत्यं शौभ्रेयः वैनते
यः गाङ्गेयः पैङ्गेयः रैवेयः ॥ तिकादिभ्यः फिञ् ॥ उपत्यर्थत्वाद्
ते तस्कन्द्रः स्वभूयः भाष्यवाददयः कद्रुष्टु कद्रवयः ॥ पञ्चग्राम ॥
पाञ्चवयः पितृष्वस्रु मातृष्वस्रुरोऽम्भयः स्यात्‌ तयस्यविमृत पयालिवा
पितृष्वसृभयः पैतृष्वस्रेयः पैतृष्वसीयः मातृष्वस्रेयः मातृष्व

कु॰
को॰
११

ऊर्णवो ऊर्णावः ॥ प्रयत्न पुत्रीयः पौत्रीयो पुत्रयुः पुष्करसः पौष्करसी
पुष्करसः कौण्डः कौण्ड्यो ऊर्णः वासिष्ठः वासिष्ठो वसिष्ठः गौतमः गौ
तमौ गौतमाः ॥ समाप्त ॥ रागवाचिनस्तत्र रक्तमित्यर्थे कषा
येण रक्तं काषायं कौसुम्भं कौङ्कुमं हारिद्रमित्यादि लाक्षारोचनाशकलकर्दमाट्ठक् ॥
लाक्षिकं रौचनिकं शाकलिकं शाकलं कार्दमि
कं कार्दमं नील्याः कन् नीलया रक्तं नीलकम् पीतात्कन् पीतकम् ॥ नक्षत्रे
णेनाय्क्ते ॥ नक्षत्रेण युक्तकालस्तत्र अणिति पौषमहः पौषी रात्रिः ॥
तिष्यपुष्ययोर्नक्षत्राणि यलोपः तैषमहः पौषमहः पौषी रात्रिः ॥
श्रवणादित्यर्थे तत्र भवः ॥ लिङ्गस्य प्रदेशेऽन्यत्र कम्यमानप्रदः कम्यमानमर्कं
मप्रदेशः ॥ लिङ्गस्य प्रदेशेऽन्यत्र तद्धितार्थे अणिति
शैशवः तस्येदमिति सन्निधौ ॥ अस्मिन् शिशु गत्ये श्वेतवस्त्र मत्स्यमांसे
मत्स्याकः सङ्घः कम्बलकारक विशेषादि कम्ब
ल्लाक सरागः कम्बलकारकं कम्बलकं विशेषादि कम्ब
स्मित् हरिद्रा शाकहारिद्रवासिनकम् कवसिकं दाक्षिकं पुत्रीयकं भाविकु
ल्लाक सरागः कम्बलकारक मानवसिक भावकं सम्
तामानम् ॥ एतस्मात्तद्धितः कम् ॥ एतकं पुनातः किम् पुनर्भवम् य
वीरस्थविकादिषु सम्भृत पुत्रिकं कन्याकालः कौन्दम् स्वाध्यायमायववाह
वाहत् स्वाध्यायमानवं वाहवम् पासाद्धितीयः शिवामाहम् पासाद्वाहत्
अपत्या पत्या स्थित्रपित्यस्य त्यक्तिनी शुभ लाभवत्साल्मदयहसुग गृहम्
हानि ॥ भौमष्टवत् ॥ लिङ्गस्य भूतवत्तद्धितर्थे तत्र कृत्य मिथ्याष्टवस्य
मेयः वैखवः वैसुः ॥ भवतक्त्र्यियस्त्र ॥ भवदीयः भवदः यदाशङ्क
याम्यानिक्ये भाक्तवः भेभष्टवस्मृतिशौनः ॥ वासुत्रपिसमायत्त ॥
कदवववाचा वास्माविकरोकरयोषि ॥ यागि वायत्तः तत्र पूरवत
भिसृत पितृः उपाः उपवत्सङ्ग उपमहं अर्कं मत्कृतिसियरयो मत्कद्यियः
मत्कृतीयः ॥ उडुलोपाणी ॥ लिङ्गस्य उडुपाणी उडुपयोर्न्यत्र
कर्मयत्नपीडया कान्तः वैयाकरणः उक्थमित्युकथ उक्थमामवेषु
कर्मयत्नपीडया कान्तः वैयाकरणः उक्थानित्यकर्म उक्थमधीते क्रमक
पीडया लाक्षिकः याज्ञिकः उक्थिकः उपनिषदिकः धातुपाठिकः लौकायति
कः वैदिकः नाडिकः नैयायिक वैशेषिकः पौराणिकः ॥ अङ्गगुणि

कल्पादिः ॥ वैयाकरणः साङ्ग्रहिकः काशकृत्स्निकः उक्तं कल्पसूत्रः याज्ञिक्य
इः लोकायतिकः ॥ क्रमपदशिक्षामीमांसासामभ्यो वुन् ॥ क्रमकः पदकः शिक्षकः मीमांसकः सामकः ॥ [illegible] ॥ [illegible] ॥ [illegible] भवतष्ठक्छसौ भातं यद्ध वैश्यं ॥ वृद्धाच्छः ॥ [illegible] कीयः ॥
[illegible]कीयः [illegible]कीयः [illegible]कीयः [illegible]कीयः [illegible]कीयः [illegible]
[illegible] भवतष्ठक् [illegible] पितृवत् [illegible] पितृं [illegible]
[illegible] पितृवति [illegible] औत्सः [illegible] औत्सः [illegible]
औत्सः [illegible] औत्सः ॥ [illegible] मालाधरजातीयः ॥ [illegible]
[illegible]णीयः [illegible]णीयः [illegible]णीयः [illegible] मालीयः दक्षिणापथीयः [illegible]
[illegible] [illegible]णीयः ॥ [illegible] ॥ [illegible]णीयः [illegible] वाह्निक
[illegible] वाह्निकः [illegible] वाह्निकः [illegible]
[illegible] वाह्निकः [illegible] वाह्निक
कः [illegible] वाह्निकः [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible]णीयः [illegible] मीयः [illegible] मीयः [illegible]
[illegible]
[illegible] कः [illegible] कीनः [illegible] कः [illegible]
[illegible] लौकिकः वैदिकः [illegible]
[illegible] लौकिकः [illegible] वैदिकः [illegible] मयट्
[illegible] मयं [illegible] मयं [illegible] मयं ॥
[illegible] ॥ [illegible] मयः [illegible] मयः [illegible] मयः मा
त्रिकः [illegible] मयं [illegible] मयं [illegible] ॥
कु. [illegible]
कौ. [illegible]
७३ [illegible] ॥ [illegible] मयः [illegible] कलेयः

मृ॒ग्यः पौत्रः शशासदङ्क शशाठव शशात् उदरः कुक्षिः उदरम् यकृत्
उदरः यकृत् सक्तिप्रत्ययस्याधिकरणमूलम् उदरस्थकवादिभ्यः सक्ति
प्रदः पाञ्चालः पौरवः ॥ ठञ्मीदृतिभंसन्तुउत्तीकस्यादपि प
द्गाच्छिलद्विर्येगास्तुतीउपनायणस्मि ॥ लिङ्गठञीद्रृठीशदिभ्य
लभ्यउकल्पाउ शक्तीदृति प्राकिकः मान्नाकिकः प्रसंभ
धुमाणिकम् प्रलिङ्गिनिमृउ प्रक्लीभंभधुः प्रलिङ्गे णनाः श
क्षारमल्प भोज्यं भक्ष्यं लवणसंसृष्टिकल्लवणं लावणं शाकं क्षीरम
यल्प क्षैरेयम् क्षैरेयी नावा तरति नाविकः औडुपिकः द्विपारिकः।
प्यटिकः शकटेन चरति शाकटिकः हास्तिकः औष्ट्रिकः राथिकः।
रथिकः मवउल्लीषुनाउपि वेतनेन चरति वैतनिकः धानुष्किकः श
पाशिकः धनुर्गृहीत्वा चरति पण्यवामिनमुद्रमूयपद्मिदृश्यते लावणि-
कः गान्धिकः शिल्पाद्युपस्थ शिल्पमिदृश्यते मान्त्रिकः पिर्यिणाउद्दनि
यउ उदृश्यते द्वगत्तीमांसउउभृगुयाम्नि काराणामः सौवारिकः प्रगन्धु
लिकः दैवागारिकः कौष्ठागारिकः भाण्डागारिकः हीउपदिदिउयपछुपी
मधुमृगे श्वः हीउदवाउलिङ्गप्रिकल्प यक्षुहीउं याक्षिकम् आभिषे
कम् मउत्तूकौ मदः माउकः भदमुयभराह्णामल्प भादम्यवामर
प्रयुणवामिनमुदमूयुणमिदृश्यते पाञ्चिकः पूलिकः णयः कल्प
णयकुः मक्तियधूरीकल्प माक्षीकः याक्षीकः प्रदिणदपदगयर
पीकल्प माक्तिः पूर्यैलनमस्थ माक्तिकं पौत्रिकम् तादिकं प्रभातिकं।
कलवादिनमुइकदेउइगुराह्नमाङ मासिकाद्दं मासिकं मासुं याक्षि
कं सांवत्सरिकं मासपह्न मासिकं लाठः याक्षिकः उमसूयपरिभाल
धार्मिकं वासि ॥ पौरीककल्पीद्वामीकल्प ॥ पौरीकः ककल्पी
कः भदभापरस्य भादमूः उनापनउि कैवल्लिकः उदक्रुउि वाद्दरि
कः। मदाउक्रुउि वैयाकरण्यमस्थ। माक्षिकः वैयाकरणिकः। उ
द्रुहृणीउउदृश्यते वारल्पः माक्षिकः पञ्चउञ्चवति णाक्षिकः। पक्षिसम्

भगवादिभ्यष्ठञिति भाक्तिकः पुष्पलिकः भैक्षिकः मातृकिकः
तैलिकः दातिलिकः, भस्त्रादिभ्यष्ठन्निति औत्सङ्गिकः औडुपमा
यिकः भस्त्रादिकादिभ्यष्ठयथयलक्ष्मि श्राणिकः श्राणा
मांसौदनिकः भक्तादणन्यतरस्यां भाक्तिकः, अगारान्ताट्ठन्निति
पारदारिकः पारस्त्रैयिकः, ग्रैषिकः, ग्रैषिकः पश्चाद्भविकः,
लः पश्चिम, पाद्यः, पश्चिमीयौ, पश्चिमीयः पश्चिमीलः,
प्रत्ययः सर्वत्रेत्यवस्थे प्रत्ययिकः मादनिकः पुष्पमिकौ मध्यः
रथयुगप्रासङ्गं वहतीत्यर्थे यः रथ्यः युग्यः, धुरयस्त्र, धुरः धौरेयः
भवप्रत्ययाधिरल भावप्रत्ययः, पश्चिमाभिहं, पश्चिमाभिवाचक
लौकिकमित्यादिप्रभृतिधौरेयः कल, पश्चिमपरलौकिकमित्यादिप्रभृ
भिकः नाभिपरलौकिकमित्यादिप्रभृतिनाभिकः, प्रतिमक्षइठव ठेधा
दिकः पुष्पदिकः रैवदेवादिकः दैवादिकः मौवादिकः औषदि
कः गौणादिकः उत्पादिकः सूर्यादिकः सोमादिकः, पक्कलाष्ठ,
पक्कलिकम् पक्कागारादित्ति पक्कागारिकः ॥ नौवयोधर्मविषमूलमूल
तुल्याभ्यां सम्मितयोः ॥ नौसमुद्रतार्य इति हञो विषाद्धत्य
वध्ये इति तुल्यासम्मितसीतामूलसम्मितैः लिङ्गइत्यादि इति यः
नाव्यं नाव्यं विषेण वध्यो विष्यः तुल्यासम्मितं तुल्यं धर्मपथ्य
र्थन्यायादनपेते इति यः वयसा तुल्यो वयस्यः धर्मादनपेतं धर्म्य
मिति यः धर्मेणानपेतं धर्म्यं पथ्यर्थन्याय्यमिति यः पथोऽनपेतं पथ्य
मर्थः अर्थ्यमिति अर्थः अर्थ्यः न्याय्यः, छन्दसः
निर्मिते इति ढञ् पाथेयं पट्टं पर्शं हयुं, अन्नाद्युक्तं रसेन छन्दः ग्र
मीतः इत्यादि इति यथा कषायः सायः, मनयाभ्यसेकम,
मधुः मधेयः मधिकः पथ्यतिथिवसति पथं पाथेयं सभा हृदयः प्रियं
हृद्यम्, पथ्यसंवत्र, पथः पथीनः संयमाभीनाम्ल आपथीनः
आपथमीनं आह इत्यादि, आपंल्लना आपथमीनमाहुः, सभासभ्य

क॰
कौ॰
१७

स अतीतं चिरमभावेदितेहमुत्पिङ्ङहङ्ग मगरुः मयूरः
मतीरुः मेघः ॥ इत्यादि ॥ उष्णादिभिरहङ्गलिङ्गनि
यः शूराः शस्त्रीयं करणीयं ॥ पुण्यविशेषणात्मे [illegible] हरं
नः ॥ पुण्यनीरः विशेषणनीरः भाव [illegible] नीनः पितृ [illegible] नीनः प
चलनादिकम् भवलनीनः भावलनीकः भवानः भावः ॥
यत्नगवादिः ॥ उपमानानि [illegible] वाचिभिः [illegible] दित्य
त्य मकरमृगा [illegible] वर्णं वामः गर्हं दधिमुखा यममुखा दि
त्यत्य [illegible] वाचकः क्रियादिहमुक्तव क्रियं वत्रः पत्रः
पत्रः पुत्रः मत्रः वंशः कंसः उलूकः [illegible] गणत्रः
[illegible] यः [illegible] यः [illegible] यः ॥ उपमानानि ॥ मधु
मीयप्रक्रियाः उपमानवाचिभिर्लिङ्गप्रकृतिः शूराः [illegible] वाणीत
[illegible] [illegible] यवत्र मधुरायामिवमधुरायत्र ॥ उक्तिरुक्तं ॥
लिङ्गमुक्तं [illegible] भुः [illegible] मुक्ता मुक्तादभा पामका [illegible]
मकदभा [illegible] ॥ यच्चप्रकीर्तितः ॥ प्रत्यासत्ति
[illegible] यच्चकर्मितः [illegible] प्रकीर्तितपदानां [illegible]
[illegible] [illegible] यथा [illegible] इतिवमत्र
भा [illegible] वाचिभिः [illegible] मोक्षं कर्म पाण्डुवहु
[illegible] मूलनील [illegible] वाचिभिः [illegible]
मोदितं [illegible] गुणवाचिभिः [illegible]
[illegible] कमलिनी [illegible] कमलवत्ता [illegible] मायुदमा
पादितं [illegible] मोक्षदं [illegible] पुद्गलमा वालितं
मामिदभा मादितं [illegible] ॥ पदानि ॥ गालपदं
गालपदं [illegible] वाकमदका वामदतं नादतं [illegible] कवः

कमकमल। गहं ओलहं सुफ्रुश्रिमिनालडिगाल्ल: ॥ निथुश्र
मिहिस्त्र ॥ निभिन्सृठयाकमया नैभहं नैभ्रुल्लं कैमलं कैमलं
मापलं मापलाभ। ओठपं ओठपं हठ्ठगमिन्ह तेपवयम
शृमडि यहठयपमनहि: बल्लिहनमसृडे मैठांहलयं ओल
लयं ओलसुभ। महलमसृठयाकमया ओलमभ। हलयसृहल्ल
पिपयमस्त्र ओघ्निडि हलयसृल्लिहलदामि: ओहलमपिलहुग
मडवत्नमिहि: श्रुाति मायवत्नुभ। माडनामृहं माहुहं हैलिहं है
कहं हैभ्रहं हैभुहं मापहं वैमहं माकहं कुमहं वैमपृं, श्रुति
कमिमल्ल: पिमशृडे हुविहं माकुं, मीनं मैनी दैवं, मधु ओथृ
यभ। ङल्लह: कमिनिस्तृयामथि क्तमिजी माडुनी मागल्ली वैड
मी फुहथ्वी दलमुहितृस्पृडिडश्रमुनामलयदहयसृलेप: ठवक
मल्लिडायमायुवामिहिल्ल। हुदयमभ। हुडयामभ। योवं ओलं
मैमवं यवामिमालडिगाल्ल: यबायमनं वत्नवामिहि: पञ्च
मिहिश्रिभत्र पिठवायमभमकरिडयडा। कहिडयडु मठ्ठश्रवमिलि
भामिमनिडि याश्रिमा नीलिमा कलिमा ण्वलिमा मुज्जालङ्क
नङ्हिलि रठवहनकिणाभाड। मृत्विमा मूनिमा हुमिमा हुम्निमा मु
निमा यनिश्ननिमा ष्लिमा मनिमा नाप्यिमा वदियरसृमर
मुनिलेप: वनिश्रडमिमः वजांकय: क्षमा पियश्निवडि
भूलय: पृमा कृमा मठमा वनिमा वंदिमा गानिमा वलडम
वडावकाश्रेसृडे हृथ्विमा भुविमा मविमा यविमा हस्विमा
क्षिविमा क्लिमिमा पञ्चामिमालडिगाल्ल: भनिपडडवीवयल्लि
कु० ऐठयककमल्लिद: भाहं डडं वीरं यल्लिहू सेनाञलेभस्त्रसु
को यं कथिल्लडिहमियल्ल। कायियं ण्वलायास्त्र ण्वलेयं।
५०

र्थेयपणाद्गुरूपोत्तमाद्वुञ् रामणीयकम् कामनीयकम् वैहृकं मा
लुह्यादिभ्यश्च मानोल्लुकं कालिनकम् मदयन्त्यैर्हैयश्च मादयकं मा
दय्यं नाटकं नाट्यं ॥ तदस्यास्त्यस्मिन्निति मतुप् ॥ तदस्यास्तीति अस्मि
न्नस्मिन्निति विग्रहे मतुप्: गावः सन्त्यस्य गोमान् गावोऽस्मि
न्सन्ति गोमान्देशः मकारावर्णान्तोपधाया मिद्वत्वस्य मतुपि वप्रत्ययो
ञ् यवादीन्वर्जयित्वा किंवान् उर्मिवान् संवान् ज्ञवान् मालावान्
विद्युत्वान् लक्ष्मीवान् मधुवान् स्वाध्वान् भूमवान् कण्ठवान् विद्वान्
उदन्वान् मधिष्वान् सुयवमान् भूमिमान् ऊर्मिमान्सप्तम्यां मतुपि यव
मान् कृमिमान् ककुद्मान् मलिनादिभ्यश्च मतुपो वत्वं स्त्रियां ङीप्
मृ: शरावती कमलावती मरुत्पत्नी जाम्बवती पद्मावती नाड्यव
ती नदी, मणिवती मरुत्वती, अस्मायामेधास्रजो विनिः यशस्वी य
शस्वान् तपस्वी तपस्वान् मायावी मायावान् मेधावी मेधावान् स्रग्वी स्र
ग्वान् अस्मायामिति किम् यशस्वी यशस्वान्, ब्रीह्यादिभ्यश्च नित्यं इनिठनौ
ब्रीही मही शीली किरणः मिषी मायी शृङ्गी शिखी, दण्डदण्डकरादि
दण्डी मणी करी, पुष्करादिभ्यो देशे स्त्रियां पुष्करिणी कमलिनी पद्मिनी
उत्पलिनी बिसिनी मृणालिनी नलिनी उत्पलिनी कुमुदिनी कैरविणी
वल्मीकमालादिवल्ली पलाशादिभ्यः ठक् जालिकः कालिकः शालिकं
वीणिकः मौक्तिकः ॥ तदस्य संजातं तारकादिभ्य इतच् मद्रस्या
स्त्रकाण्डविमुक्तकः स्तः सुमुक्तनवाड ॥ ऊर्ध्वविक्रिके, स्रवान् लुनवान् पा
कवान् कण्डूवान् सुकृत्यवान् लज्जायवान् कामिन्द्रयाद्यस्मिन्मतुप् मवल
वान् गोमवान् मध्वादिभ्यश्च मधुमती नाम नदी नाम ॥ तकवान् स्वाङ्गान्मतु
प् भूपवान् श्रीहल्लिकृष्ण पक्षी पयस्वी ककुभि यवण्डवृन्दादिभ्यो मतुप्
तक्षताप्नुः कटी विकटी मकी कमी रथाभ्यां प्रत्ययोः रथवान् अजवा
न् मखवान् यज्ञवान् सत्यवान्, रथादिभ्यः कृपाणिर्यजम्मतुप् रथिकः

त्यस्त्रीरिव ऊ॰ चित्री चूलिहल्वका मज्ञः पटः चुडुज्ञ्चहृङ्गञ्जालः
सिपालः प्रद्रलः भ्रूहस्तुङ्क्ति । पाड्वः पावकः सिपी । सिध्मादिह्य
श्च सिध्मलः गडुलः वातुलं मत्र पिङ्गलः श्लेष्मलः मांसलः मद्रलः ।
वत्संसाहं कामबलिनि: वत्सलः अंसलः पेमलः बलवान् । फेनादिला
ल यवापत्सुर फेनलः शामादिह्यः शाजे शामलः पिङ्गलः मधुलय
मधुलः पर्णश्या पर्णशाला कर्णलः मकलः वर्त्तुः ऊर्ध्विउत्थ (वत्सल)
स्त्राभञीमत:। लोमपामपिच्छादिह्यः शनेलचः लोमशः वद्धुमः द
रिमः पामनः पूरुषार्थञ्जनियमश्चामा पक्ष्मना बलिनः पद्धुलः पिच्छि
लः फेनिलः एलिलः तुण्डिलः उदरिलः पङ्किलः सिकताशर्कराह्य
मञ्च सिकतिलमिम: सैकतः मकतिलः माकरः ऊषसुषिमुष्कम
धुनापमापनरावीमधाग्रुहेरः ऊषरः सुषिरउइति पोमलेपि मर
मलमिडिवड। कम्बुमधुद्रुघस्र कम्बुरः नापाञ्च्छनापरः। उत्तुङ्गा
त्राद्वरः मधुरः। रजःकृष्यासुतिपरिषदो वलच्। रजस्वला वलोविशिखी
ज्ञः कृषीवलः पुत्रशीवलः परिषद्वलः। दन्तशिखाच्छंज्ञायाम्। दन्तावल
दमी शिखावलमयूरः ज्योत्स्नातमिस्रा शृङ्गिणोर्जस्विन् ऊर्जस्वल। नत्तुनावडश्रा
न। नदमादभूहाङ्कुल: नडुलः माड्रुलम। (हिन्दुडनिमम्मश्लिलाशि
तुलम्वलनमिमलिनमलीमसाः। व्रीह्यादिह्यश्च माद्रिम्व उमत्रि
यशुः माउलिम म क्लिलवधवः तुलश्री तुलम्बलः मेघश्रियः मम
गोमी मलीमसः रूपादाहतप्रशंसयोः रूपिनः वादितः पक्ष उत्त्रयिक
नी वदी लेख्याभिहिरोमशः हेक्त्रीगतिः ऊर्मभी। ऊर्णाया युस्। अहमग्नी।
ऊर्णायुः मादमः वहुलग्रन्दसि। भाल्लुः भाल्लुः। वाचोग्मिनि। मयः कल्नुः।
गत्यर्थ
वाचोग्मिनः। वाग्मी। मुलाद्दृक्क बहुभाषिणि आलजाटचौ बहुभाषिणि कृम्भ
वाचालः वाचाटः स्वामिन्नैश्वर्ये स्वामी अर्शआदिह्यः मतुपः
अर्शः पापः दिमादिह्यः दिशः गुशः पामा। उत्विवलिवर्तेः।

दुचितः बलितः बष्टितः। षष्ठं पूरणमिदम्। षष्ठ्यः पूठत्यः। त्रुम
नित्यं पूर्वं माभुविहयोगोतिमायां संभवेत्स्त्रिविवक्षायां ठयतिमतुटा
ठयः। लेमसः गणस्तुला षष्ठा पूमयावी भागुः सप्तमितः
मसः संभवः सप्ती गोभाग्॥ द्वितीयः॥ द्विसंख्यावल्लिङ्गेती
यः स्यात्। द्वितीयः॥ त्रेश्च॥ तृतीयः॥ सहस्रायवल्लिङ्गे ॥
प्रवल्लिङ्गे भ्यागमो थुः॥ षट्कतिथुः॥ चतुर्थायाः सहस्रयः
डयस्य थागमः स्यात्। ससमस्रः षट्स्वरायिलिपः सप्तगः। रा
गाणसहस्रादि सः पञ्चमः। तुवनम् षष्ठेडित्थम्: सप्तः सप्तमः
षष्ठमः बहलितत्। सतुर्थी पञ्चमीति। बहुपूगगणसंघात्:
प्रवल्लिङ्गे तिथश्चथूत् बहुतिथश्चेति। यावतुर्यावतिथः। यावति
थः ज्यवतिथः॥ कतिपयात् डट्॥ षष्ठाप्रवल्लिङ्गे थागमः स्या
त्। इत्यत्र षट्कतिकतिपयात् डः कतिपयथः कतिथः॥
विंशत्यादिभ्यस्तमडन्॥ षष्ठ्यवल्लिङ्गमडन् स्यात्। विंशतितमः विंश
तमः ठत्रयश्चेति पूर्वस्त्रादिपर्यायेपि विंशः त्रिंशः विंशतितिं
मतः मत्तुविंशत्। षष्ठुं मतः सप्तिः सप्तरमीति नवति विंशत्यादि
न: ॥ नित्यं शतादिः॥ षष्ठ्यवल्लिङ्गे नित्यं तमल् स्यात्। शततमः
सहस्रतमः एकशततमः द्विसहस्रतमः। मासाधमाससंवत्स
रेष्वपि मासतमः अर्धमासतमः संवत्सरतमः॥ षष्ट्यादेश्चासंख्या
दे॥ षष्ठ्यादेः यवसहस्रादेः षष्ठ्यवल्लिङ्गमल् स्यात्। षष्टितमः एकषष्टः
सप्ततितमः ठत्रादि षष्ठ्यवादेः विंशत्यादेस्तिविकल्पात्स एकष
ष्टितमः एकषष्टः द्विसप्ततितमः द्विसप्ततः॥ पञ्चमाद्यासन्॥ ॥
किंयत्तदो वहूनां षष्ठ्यादेः मवतां प्रश्नपञ्चमीस्थेहमत्र सास्यात्॥ उडतः॥
किमसुडेः परस्यै डः स्यात्। कतमडः यतडः मवडः विश्रुडः
उतमडः यत्तत्रिमादेः पूर्वनिपातस्य उतडुं उतयडः॥ चितति
संख्याविल्लियावक्रेतेडः परं त्ये षष्ठ्यादेः मवतां प्रश्नकिंवदेषय

ताः सद्गुरुः ॥ उमा । ईश्वर उवाच । सप्तद्वीपवती भावस्य तेजसिद्धि
मङ्गल्यया: देवरूपाद्रिणा सत्यवाक्यवर्त्तनः किंवक्तुं दयया यः प्रोक्तः
उवाच सत्यायामुदतभा विनष्टिरिद्द ईश्वरदेवद्वन्द्वमि उक्तः यदुः प्रभुः ॥ उ
वाच ॥ उमादिपुत्रतमा तः सूता क्रमिद्भवयथाविधिभवाद्यमः
उक्तः ॥ देवदेवमाकरणमा ॥ उमादिपुत्रवाक्यस्य कारणं प्राप्तोऽसि,
तत्सद्गुरु प्रभुः सज्जातविधिकिं वृत्तमा भवलिङ्गदेवान्तरस्य पृ
देहमपुत्रिपूर्व प्रसिद्ध प्रसिद्धः पगतः महेशः पद्मविहारं भवे देवतां
यतिः भवत उवाच: यतिः उत्पत्त उवाच: उमिलाखिलहा
विदर्भं कृयाः पंचतत्त्वमिपूर्व उमिलाप्रमात्मीयप्रकन्दादिपास
याः पूर्वलोकद्विलोकद्विसूत्र उदिसूत्र उमिलायतः कन्दादिः कन्द
देहपूर्वीयतः यत उदितरत्नौ वह्निहः वहतः भवतां प्रजाद्भुता
इ पुंवक्तव: भवपूर्वः भवतः उत्पूर्वतः ॥ इमपुत्रः ॥ किंवक्त
भवतामहः सपुत्रदेहपूर्वाः कृत वहत भवत उत्पत्त उत यत
तडमिता यत प्रभत प्रज्ञानविद्वहये: इति ॥ उवाचः ॥
पूर्वद्या सपुत्रद्रव्यपूर्वा इवतः प्रसिद्धा उत ॥ किमः ॥ पूर्व
इषा उदे: कृः कृत कृतमावायं प्रयोगः ॥ पूर्वम ॥ किमः सपु
पूर्वायत यदयः पूर्वा किमस्त्र क्वकस्मिन्काले ॥ कलौ किं भवयदेक
देहायत ॥ कालविषयेऽहायतपूर्वा कस्मिन्काले कतम
वत यत्तापकता पूर्वत भवपूर्वभेदउत पूर्वाभिदि उत्पुरत्नभदेवे
मि मत कलौ किं कस्मिन्नम कृत ॥ उवाच महेश्वरातनीमा ॥
सपुत्रद्राद्रिमः कलौ दिप्रथयतनीमः पूः ॥ रक्षितउत्ता ॥
उवाच देवकरयोऽतउता उदितमाहूत प्रमितकाले तद्दि
उवलयकलौयः पपना उतनीमा ॥ उवाच किंदेवपकदः ॥
पुरुहे वमः कदः प्रकारवमनेउता प्रतिभक्तवल उकमा कथं ॥
तनीमोऽत: स्मृतौ ॥ सपुत्रद्वाकुलदेव उत उतनीमा ।

कू. कौ. ३४

किमप्रदिवयीशूत्र उदि कदि ॥ श्रकवयमसेउवा ॥ भवनाभ्रः
घास्त्राम्भिद्मति भवषा उठयघा उषा यघा पटघाश्वभयरु
उरघा मांत्राघाणाउशूत्र नकणा ढ्रिणा धर्मेत्रनाढिद्दढढेठ
वा पेठा यढू ढ्रिढिहामणाणमश्रे ढ्रणा ढ्रिणं नकाढूहमश्र
नकणा निकटं ॥ महप्रहानियाहत्र ॥ महः पनद्यगतिनिय
मः पनिहूवि पहू प्रवेहू रहेहू तिउरेहू रयनेहू रणेहू रुरेहूः
नेउमाण्डेनकहत्र ममानेदनीति ममानमहूदनहेहूमा।
ममानश्रयमहर्वेनियाहत्र महः प्रवप्रवउरयेवद्येहेहूमाउ।
उरापुनि यूहयी उयीस्वपनाह्मः प्रवस्थिवद्ये पऊउ प्रवउर
स्थिवद्ये पनानि उरुभेयद्येममम। उठं नेडंम निमयः पर
उठंद्दामदहेवाहेहूमाद्येहूविहूपूहयी उदमस्राकरः पनिहूवि
पहू प्रवाह्मृहउरेउमयनाण्रेहयेउरेहेद्देवानहूमा। प्रवेहू
विहादि ॥ पुम्याह्मयश्र ॥ प्रवाणनायसद्देहः मयुषी प
द्रुमी पूवमाउहेह्मिमिह्मकलनाहेपभाउ।पम्द्रहयोनिया
हत्र नयांहूमाउ। पन पणापवाह्मिमाश्र पनपाउ। पनः पणभा
उ। पणः पुयभाउ। पवः पामद्दह्मयिद्दहत्र पनमाद्दवः पा
माह्मम पनः पम पणाह्मदि पयोह्मदि पूणनाह्मदुहह्मा ढ्रिषी
यामद्दह्मुनामयि नयांनेउह्दहत्र, प्रवाहउमद्दरमिमश्र पर
उः पश्रिमाह्मपुष्पाहूनाह्मिनाह्मिय प्रउ। पश्रानेमश्र पश्रानिउ
ति मश्रानवाः पश्राह्मं पश्राह्मम पश्राह्मदि पश्रावउहयिह्म
हत्र उद्दरनवाह्मनं उद्दनाढियूहीहाह्म नवमनवाउ। नकिलम
हृदम।पुदिय हकिलश्रवमनि ह्मकिलदि उउनाह्मकिल्नः
मयुषी पूवमाउहेहिमाह्मिवुरुषयनरः श्राउ। उदुनेल पुणेल
हकिलन उरुश्रमयुषीपद्रुमी पूवमाउ प्रवाहेनिनिमहूहयी,

ङ्मूर्ग्रेधाप्तम: उपरि उपरिष्टात् द्वितीयायामुड्ठीरपिष्ठत्ते उपरि
पद्म ङदिवा मेयमनामणरप्रचाप्सान्नेकिवतुग्नपुष्पाद्गुरापदने
भूषभुप्पूष्टयभूलकाभूग्ड भूका ठिफूठि पद्म प्रगाः रमूंवा ए
वंप्रटकाञ्टच्छि ठिमिङुलक्षद्विङलकीठि ङप्रगुङद्भ्रूीप्रटयभूपिलु
क्षिमठि विमिङुरुहयाम्न्हेरलेपङ्ष्टाणीनिचैमिठिकंनिकदाष्टपि
नियतौ ॥ प्राप्नुवन्ति भावप्रत्ययः ॥ प्रदेलिङ्गमापृष्टमाप्नः ङ्
वक्तव्यमिष्ठेमेयःसु इमेष्ठोर्द्वयोरन्यतरस्मिन् उत्तरपदे: कतिङवक्तुमि
ष्टे ङेगाकृष्टाप्तलिलेयः प्रथमेषामादिमयोरन्यतः प्रष्टः प्रष्ठम:
प्रथमेषामादिमयोर पटुः पटिष्ठः प्रथमतयोर्गतिमयोरन पटु:
पटीयान् उत्तरपदेगुणवाचिनविभेष्टे ङेनेद धामकठम:
मन्ङ्रङष्टाणि वदेतिष्ठयस्मेगाणिलेपेवदिष्ठ क्षयिष्ठुक्षुद्रेयिक
रागमस्रष्टे क्षयिष्ठः क्षयान् भूमभूष्टम: भेष्ठः भूयान् ^नेदीयान्
वृद्धीयमवृद्धनिष्ठ, ष्ठ्यष्ठ ष्ठेष्ठः ज्यायान् अन्तिकबाढयोर्नेदसाधौ नेदिष्ठः साधिष्ठः
वर्षीयान्, साधीयान्, युवाल्पयोः कन्, कनिष्ठः कनीयान् पक्षे यविष्ठः
यवीयान् अल्पिष्ठः अल्पीयान् विन्मतोर्लुक् उपस्त्री
ङयिष्ठः भस्त्री मतिष्ठः गोमान् गविष्ठः बहुरथिमतुरेव ण
वान् ऊनिष्ठः त्वग्वान् त्वगिष्ठः प्रथंङपीयानित्यादि प्राष्ट्रा
ङष्टया ङङकिमाङङ्नाद्ध्याघादाम्वद्रव्यप्रकर्षे किंतरां
किंतमां प्राह्णेतरां उच्चैस्तरां नितरां पचतितरां प्रथंतमां ह्रस्व
विमिषल्लनेष्टे उत्तमपुरुषेवक्तुः प्रशंसायांरूपप् पचरूपः प
टुः पटुरूपः पटितरूपः पचतिरूपम् ॥ कल्पयोर्धामः ॥
क. ईषदसमाप्तौ: विदुद्धम: पचतिधामम् । देश्यदेशीयाः कल्प
कै. देश्यदेशीयरः पटुकल्पः पटुदेश्यः पटुदेशीयः पचतिक
३३ ठिकल्पमित्यादि ॥ कुङप्रवेमाणए ॥ प्रकृष्टः प्रकृष्टतरी।

प्राक्डमाहु

प्रमादयोरकच्कुत्सिते वा सकक: सककी सक: अश्वकस्तु
इत्यादि सर्वनाम्नामकच्प्राक्टेः केवलस्य सः केवलकः। उच्चैस्तमामुच्चकैस्तरामित्यादि
तत्कदिहृतूत्तम तत्किंत नठः भवित: तः स्थितः इति तत
स्वपतिमाल्लमित्यादि द्वयमम्लप्रमद्दः द्वयः अन्यद्वयम् अन्यत्वं
अन्यमाहं लालं यन्वमन्मिहामप्न यौकचं दश्मिरं भूनमद्वयमं
दश्मिद्वयसं इत्यादि यदुद्रिकृ: यरिमाल्लवतु: यद्दमरद्धूर्त यावा
न् इयान् त्त्यावान् तत्मतयतुरिप्न इयतुवतल्लोपः इयान्
किमिदियतु: कियान् एकवचनया: संख्याया अवयवे तयप्
पञ्चतयम् द्वित्रिभ्यां तयस्यायज्वा द्वयं। द्वितयं त्रितयं त्रयं तत्वदत्त
त्रितयम् उभय: संख्यायाः परिमाल्ले किंमि इति: कति विद्याः बहुल्लेत्या
भूरकासुमसम् बहुम: कुतिम: सल्लम: एकम: बहुबहुतांश
त्: संख्याया विनाएकवचनानुग्रहवीप्सायां द्वैघ्री द्विर्म तटति यठ्
म: पादंपादं ददाति पादम: पक्षादस्वदेव तद्भवीनां प्रयोगाग्निः,
अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः अशुक्लं शुक्लं करोति
शुक्लीकरोति शुक्लीभवति शुक्लीस्यात् एवं मालीकरोति प्रदयम्
दीर्घत्वम् पट्वीकरोति पटूभवति दमेडोली कर्तृकरोति, कर्तृभाति:,
सर्वं भस्मं करोति: भस्मसात् वाह्निसात् वधिसात्, इत्यग्नीवत्सर्वम्,
गुरुवशीकरोति गुरुसात् देये त्रा च गल्लमयहुचित्रवत्सलांद्र
दुमुरत्रिपम्यपनयान्तम् संख्यायाः क्रियावृत्त्यावृत्तिगाने कृत्वसुच्
पञ्चवारान् पञ्चकृत्वः सप्तकृत्वः एकद्वित्रिभ्यस्तु सुच्यन् द्वेवर्या
द्विः त्रिः सकृः एकस्य सकृत्तवम् एकवारं सकृत् उत्थंभी
स्त्रिमसुकृदनपञ्चमनाहुतृपानिमति सलिङ्गसंख्याकृत्। ॥ ॥
इति तद्धितप्रकाम: समाप्तोयं कत्तृकोमुदी ॥ इति तद्ध ॥
तिसूयमेत: ॥ मुनभनुभवलागाडां ॥ तद्धंपट्टेभ ॥

ऽ पवचनमिन्द्रभीरुयवृद्धकीभवति ॥ भवन्तेभसम्राजोविभु
र्वधिवचनसूत्रः वचदेवेवचनमिः भवत्युक्तयरमेदे ॥ स्त्रियाम् ॥
सुपादपत्रिसमाप्यस्यप्रत्ययः ॥ ऋन्नेभ्यो ङीप् ॥ ऋन्नेभ्य
नान्तेभ्यः स्त्रियामीप्स्यात् ऋतः कर्त्री हर्त्री दण्डिनी छत्रिणी
हन्ता उष्णिक् देवविमानानामस्मात् कर्त्री कुर्वाणा कविकृत् महनीकी
किला ॥ ऋन्नेभ्यः कर्त्रा हर्त्रा देवस्या कर्त्री नामन्तस्येवापि डः
कर्तृ नामन्तस्येवाकिं भवानकुद्री ऋतः किं कर्त्रीकर्तृत्वदर्शनात् ॥
दण्डिनी ॥ दन्तोहेतोर्हलन्तस्त्रियामीप्स्यात् कर्त्री हर्त्री दण्डिनी
यशस्विनी भगवतीत्यत्र भवति भातेर्वमासदियनदा ॥ वनो र च ॥
वनो ङीप् स्त्रियामीप्स्यात् रेफश्चान्तादेशः धीवरी पीवरी ॥ नसंख्यायाः ॥
पञ्चैः स्त्रियामीप्स्यात् , त्रिभिः पञ्चभिः नलोपस्तान्तयुक्तवत्सु पञ्च
मनुस्व ॥ मनः ॥ डाप् पामा पामानौ सीमा सीमानौ ॥ अनो ब
हुव्रीहेः ॥ अनुपधा अपवा अपवानौ बहुराजा बहुराजानौ ॥ उपे
धाम ॥ अनुपधानुपसर्जनबहुव्रीहेः स्त्रियामीप्स्यात् दामा दामे दामाः
अपवा अपवे उपसर्जनबहुव्रीहेर्डीप् वा आप्सत्रयामः बहुरी
वरी यज्ञेप्रवाहयति बहुराजीवा बहुराजीयानो बहुराजीका बहुराजी ॥
धात्वाल्लोपि कर्तृः ॥ अनुपधाल्लोपिरेवबहुव्रीहेः कल्पसूत्रवा
स्यात् बहुराज्ञ बहुराज्ञ्यौ बहुराज्ञः नश्यकन्नी नश्यकर्तृ ॥
उदृकपादवदुत्री ॥ पदनस्त्रियामीप्स्यात् गौमती गवती विदुषी
पचती पचती देवती ॥ पादो वा ॥ पादन्तस्य द्विपदी द्विपात् ।
ऋतः ऽन्तादर्शि नान्तस्य द्विपदा ॥ पत्युर्नलोपः ॥ पतिर्नवयव
सुपादसमाप्तः ॥ पुरन्ध्रि ॥ युवत्याः समासान्तो विंशतिः युवतिः
क. पत्युर्नलोपादौ वरप्रयुवा नगरी ॥ नारी ॥ द्वन्द्वपदरंकयवदि
कौ. द्विपादरूनारी ॥ पत्यैपकारः ॥ एकमात्रामीप्स्यात् वासिनी ऊरुकरी
५८

पुगनादिः पुष्टयी पुम्भिकी उदनवह्न वामिश्रा ॥ पुष्ट ॥ उमायस्थापह
विकल्पः सृष्टियल्लेपः गानी नेदवह्न गानुा ॥ भूमा ॥ भायनमागमः पु
गुप्टीशहये पुयनागभेवाभूाउ गानूायनी गानी ॥ कोरदूषभिमा
कुकउ ॥ उमाभूमामिडिडुनिवउभ कोरदूषायनी पुभयायनी भा
कुकायनी ॥ लोहिउामिकउजुउः ॥ लोहिउामिहः कउयदउुहि
पुउुहलाुंरं भहये उमा लोहिउायनी भांमिहयनी वाहुहायनी का
हयनी ॥ पुवहुमय ॥ मण्डूकप्रुहभूमामिडियउउ पुवहु
पुवहुयनी ॥ वउश्रीम ॥ वाउकुमबभ्रुवंभहयेवउपुमेमिपा
हुउ वउश्री ॥ वयमिभुषमे ॥ भुषभयेवामिनेलिभ्रुमीभूाउ उ
भागी किमेमी वपूली मिरुली पुमुजामेवभुउ मिभुः ॥ द्रिगिः ॥
पुमुजाद्रिगिनीभूाउ पक्षभाहुल्ली द्रिगायनी ॥ मदुशवजुग्धी ॥ भुवु
नवनुभहयाउालिग्धुमीभूाउ नउकी यनकी ऊनमनी पुहुमनी ॥ गाय
नः ॥ पुभुमीभूाउ गोमी भभ्रुहयेहुमिडियल्लेपः मश्री नमी भदी
उकुल्ली पुश्री दयी गयथी भकयी मनश्री पुमुडिगल्लयभ ॥ उकुशी
कुणभेनम ॥ उमुजाद्रुकुशीदेरीभूाउ नभ्राउाहमः ऊद्दिश्री थपिश्री ॥
याभंयेगीयणभ्रुमुउ ॥ पुभंयेगीयणभ्रुमुहाांभूाउ पमूभापी
पमूभापा भकेमी भकेमा उदन भपाभ्रा वकुशीदेरिहेय पुडिभ
पा गाहमीवायाभुः भद्रुभी भद्रुम भगाही भुगाहु ॥ गामिके
पनकठाभ्रुणद्धमउुभुमहुः ॥ पउमुजामीभहयेवाभूाउ उम्ना
मिकी उम्नामिकेहमि भम्कुउाभ्र कल्लालभम्की कल्लालभम्क क
यरभल्लिविषमरेहिमिहभ कवरभम्कीहमि ॥ भविहभानन द्रुवा
न ॥ रंमुमाभ्रुमुमीनभूाउ भकेमा विहभानकेमा पुकेमा ॥ कुह
मिवक्रुभ्रुगाउ ॥ कुहहुाहमुभ्ररभाहुभ्र उमा नहकुहा पभ्रुल
थनाभामियपुा कुहापुरमदउमगाल्लहुलकररकुमकुह
मिः पुमुडिगुल्लयभ कभ्रुगीवा ॥ पउवउेगहिहभ ॥ भ
भभद्रुहि पुभीभहयेहरागमःभूाउ पभ्रुवश्री गहिल्ली ॥ पडिय

त्नीवत्कुति ॥ पतिवत्न्यन्तर्वत्नीवन्द्रुकयां उक्ता पतिवत्नीमतः रक ॥
पत्युर्नो यज्ञसंयोगे ॥ अस्मदीशात् नञ्जात्रादिमः यज्ञसंयोगे पत्नी वि
भाषा सपूर्वस्य [illegible] गृहस्य पतिरियं ॥ समानादेः ॥ [illegible]
[illegible] समानः पतिर्यस्याः सा सपत्नी समानस्य [illegible]
समानादिगणः ॥ पूतक्रतोरै च ॥ समानादि
[illegible] उक्ता [illegible] पत्नी [illegible] पतिः । उपमा
नाद्वा ग्रामस्य पतिः ग्रामपतिः ॥ [illegible] याम् ॥ [illegible]
[illegible] याम [illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible] ॥ [illegible] ॥
पिशङ्गी पिशङ्गा ॥ [illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] । [illegible] ॥
[illegible] ॥ [illegible]
[illegible] नीलादोषधौ नीली
[illegible]
[illegible] ॥
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]

315

[illegible] गार्ग्यकी [illegible] पुंयोगात्किं [illegible] पालकान्तेभ्यः
[illegible] वाच्यः । इन्द्रवरु-
ण[illegible] भवशर्व[illegible] [illegible] वाच्यः । इन्द्राणी वरुणानी
भवानी शर्वाणी रुद्राणी मृडानी, हिमारण्ययोर्महत्त्वे महद्धिमं
हिमानी [illegible] यवनाल्लिप्यां यवनानी, मातुलोपाध्याययो-
र्वा मातुलानी मातुली उपाध्यायानी उपाध्यायी, [illegible]
[illegible] क्षत्रियाणी क्षत्रिया पुंयोगे तु क्षत्रि-
यी [illegible] शूद्रा पुंयोगे तु शूद्री, [illegible]
[illegible] ॥ क्रीतात्करणपूर्वात् ॥ [illegible]
[illegible] करणपूर्वात्किं [illegible] ॥
[illegible] ॥ [illegible] पुंयोग-
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] ॥
[illegible] ॥ [illegible]
[illegible] किं [illegible] क्षत्रिया [illegible] किं
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] मालायवली [illegible]
[illegible], पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ [illegible] ॥
[illegible] ॥ [illegible] ॥ [illegible]
[illegible] किं [illegible] ॥ ऊङुतः ॥
[illegible] किं,
[illegible] ॥ पङ्गोश्च ॥ [illegible]
[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥

कुलेश्वरं महेन्द्रः लक्ष्मीन्द्रः वामेन्द्रः । मदमदिरामदिरापानञ्च
त्रिवकुलेम् । मदेन्द्रः मदिरेन्द्रः मदिरेन्द्रः ॥ स्वयम्भूमदिरापानं ॥
रक्तमातृर्कुलेश्वरं करठेन्द्रः कपाली भुषितेन्द्रः ॥ वामत्यागेव
मंत्रयामं ॥ यमदंत्रयाक्रलेश्वरं मद्यवाद्यः चन्द्रवाद्यः मं
त्रयांकि वज्रवाद्यवियमं ॥ वलिपः स्वमुद्रमास ॥ स्वमुद्राकुले
श्वरं स्वमुद्रः ॥ उडितदमं ॥ उडिमूर्तिमद्यपरकमः ॥
कुञ्जवाप्यवाभ्यदेवेननिष्टमं शुभम् ॥ साके ०११८ ॥ ॥

हृ
को
३१

ॐ नमः शिवाय ॥ ॐ [illegible]
[illegible] १ [illegible]
[illegible] २ [illegible]
[illegible] ३ [illegible]
[illegible] ४ [illegible]
[illegible] ५ [illegible]
[illegible] ६ [illegible]
[illegible] ७ [illegible]
[illegible] ८
[illegible]
[illegible] ९ [illegible]
[illegible] १० [illegible]
[illegible] ११ [illegible]
[illegible] १२ [illegible]
[illegible] १३ [illegible]
[illegible] १४ [illegible]
[illegible] १५ [illegible]
[illegible] १६ [illegible]
[illegible] १७
[illegible] १८ [illegible]
[illegible] १९ [illegible]
[illegible] २० [illegible]
[illegible] २१ [illegible]
[illegible] २२ [illegible]


[illegible]
[illegible]
[illegible] ३५
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ३७
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ८८
[illegible]

[illegible]

यदृत्पवाणदेवैषमृदृत्पवतिवद्भूते पद्मिन्यभूर्विन्दोर्प्रमोदितैः पद्मप्रिताद्
वभा ११ मणिर्येनिन्नुयेनान्वियमभूत्महभवितृयं धवाद्वादयदृभूः प
एसुदृनिलनवभा १२ कबाधवन्नेवनूपिकन्नेलवाशरणूते धायःस्रा
स्रालयदृदःसपन्नीरमकैकममा १३ शङ्खिमङ्गठिमानःकःपरधल्लेप
लीविनाभा धृतीयैरल्लकूरैमदक्कैरैविक्रुधल्ल १४ उदृमेधूणमभू
ष्टाह्ण्णूरनकरःक्रमिद्रा कैभुठलीविरह नियपलेदविरम्भुठिमा २०
धयद्धेमदलैकेमिद्धेवाधूठलठगिनः कीर्तमलमपाठैवैरमाउं धूस्रूना
मरैः २० मुल्लैःपुलठवेमूंमांनैकमलठपवरेतःलपा प्रहूपवूमममीमर्णैः
परमञ्जैःमूवादरैः २१ उल्लैपरैयिडपिठूलूवृयैःमाशनीमयैः नलद
एलवैठैलसन्नलनभ्मूदयैःक्रमिद्रा २२ हैगःपरैपडपनवंमांदुःपा
यमाण्धिरः पानभधूलणःकिंयंमूपीदयैएलोकमामा २८ नैप
ठगायकीनामापुनमद्धिवदमिरभा पायवःकिमलल्लूरमूममटाहदूर
वदे २४ विरंधिवमनैमदूगूठैधनःधकमूदे उधूवैल्लानुरसौप्रिहन्दृ
लीडिपयःकल्लैः २१ विकएभूंगरीयांममपिल्लेकैनभहूदे पविदृम
पिदृदृरनममूविएक्रवीमा २२ मुल्लैःमूभूवन्नुनुल्लुयदृगुल्लवादरैः
गैयनैपयदृद्भयिदविद्रवैल्लवाद्यदिः २५ उदृमर्मुधमायादिदृमदूपभू
दैयद्रि मदूःरमीदडिशपःपामठरनैनमूयमा २६ मवदृगुल्लवा
दमेमलकभिषूमदेदामा मल्लिर्पूद्विगल्लैवादोपादपीएयेमैठदे ३०
उदृमंमुमिरैवविपमैठिठवंदूलभा गदगूमनमंकूदाळल्लंविलूकयदैवि
पैः ३० धायःमवठयंभद्रुदिपल्लाःमंमजदःमदामा मदूदुःपडिदः
पादभ्रिदंदमैरम्लदमूदः ३३ गठडिवशांवैयाहंदालैयाठडिवान्निति
मजूर्नदपल्लवक्रुठधल्लंकिलल्लैमनै ३३ दठगःस्रादूनहायैविक्रुद
पिमदद्मः गैमयंमीविवामैपिदधापिनमनैदरमा ३८ गुल्लन्नूदूदि
एनुनांमएडिकैवनाक्रमिद्रा मठैएकंठल्लंठग्रंककिराापिनगलहदे ३५

पु॰
४

प्रगम्भ त्वम्भ मेठडियश्चेवनउ ब्राणाः यत्रेम्भनमयमयंमकम्भिनउत्रेधूमि
मनम्भिनेनभनृतुपरयाम्भुपल्लीविनः वन्तिकुक्नेनककेहः मन्दयत्रिनकेकि
र्लः ९१ मत्रेधमनुयपेभांभाक म्भिकणनागमः भरभांमेडठमयवम्ने
ध्यःमयनम्भिरः ९२ एयडेमनडेभाकुःकलेनाहूपिमनडः ठवेम्भ
मानभम्हानभहूंसमम्भमाकुः ९३ उम्भेरवमरेवमुमुठंभ्राम्भापका
रकम(उम्भवेवम्भयठामुयाहूं मडभंभूते ९४ मनुभृहूभमुहणे
नमदस्याभः धूमीमत्रिणेपेम्भेवावलिकिम्भवियदः ९५ नकममिम्भ
डांमेडः भ्रमरहूपकमम उेयेधदूडमथनुः मधिरमृरम्भाबूलेमा ९६
मल्लीयविध्याययभादम्भूं मृम्भेठन्रम(मूनेविदम्भमानेव दिगाप्रतु
लम्भभाग ९७ पुरुंभूर्मलेनेम्भिमामम्भयत्रिनठत्रिडः मधुमम्भीत्रिगी
नेदेपेध्रुडेनुधम्भडः ९८ मदडेयाम्भमडेलेयम्भामूम्भूनलेभः मनुं
यात्रिधकमेनम्भकदिविवम्भुः ९९ मम्भामम्भ्रारयाम्भ्राम्भ विद्यां
गदेनजेयामकनाभमम्भुः मिठुयम्भूमिमहूविवामेभानेभानेनेम्भवः
मनुमम्भुः १०० मामम्भमूयवमेनभम्भेवादडेडमनवाहूयुम्भुडवेम
गेठवडिभाम्भवम्भम्भुदगेदिभायम्भहूडिमम्भः १०१ ममःमंम्भूम्भ
लगडिकिलकेमिम्भूनडिनः भमानायाभवयविवयमिमहूभयिणिय
भयंम्भभूम्भूरेम्भम्भलयेविमयाम्भहूभायः मुकःम्भेकवहूंमुठवडिनक्ककः
कमिम्भयि १०२ एनभयियरम्भंदःभमेभांविदठमेठवडिदम्भिडम्भेबानम्भ
करीडरेयाम(मनयणेवमविम्भरम्भणडेरेहभ लनयडिमडमेवाम्भमभट
हगाहे १०३ कलकमेम्भयविम्भभवमामनम्भठवाठवत्रिकिलम्भवमजी
वडम्भः मम्भमलिलम्भडेयकम्भेभृम्भीयाम्भपहूडेमविरकीमकवम्भूम
ह १०४ उयंडमममम्भवेनकविकेविनिदिम्भ मम्भामुकलिकनामम्भ
म्भडंकविभानम १०५ ॥ समाप्तं मदम्भानुमडकम(॥ ॥ ॥



श्रागडश्रालदर = प्रभञ्जितिः भलिलभकरंभत्रिध

डःक्रमेघ्यःमहेमाजःकुपद्रकेरलैःश्रालिलिठिःभुप

लीयाः डष्टसुरमघ्परिगालयवृहकमुयमाथाका

भाञ्जाद्दिभूल्यपजपश्रबुडगामेडरेध ॥ ५ लडंवंमेघु

यनाविदिडिभश्वरावडुकांरलगाभिद्गंभूजडिप्रकंधंकम

डुंपंमध्यनः डेगाखिंहुयिविविवमाञ्जवबुनडिंडंया

ह्लवकूपरभृणिपुल्नराठभलवुकमा, १ मडभुगांछ

भभिमरणंगडमृधिंदथ्रियाय:मकेमंभेदरणनपडिहूण

विलेविडमू गाजहूडेंवमडिरलकनाभयके स्रुवाश्रृंता

हिहनभिडडदगमिरव्रद्विकणेडदमू ७ श्राभाञ्जडं,

पवनपमवीभद्रदीडलकडाःहेविभृतेपविकवनिडः

भहयामभ्रभडः कःभवहुविरदविप्रांड्रयुपकेड,

लयांतभ्रामकेभृदभिवणेयेःपगणीयकेडिः, ३

भ० पुपकवबिधयभापमभंडक्रमालिहूमैलंवहेः वंभा,

ड० रभ्यपडियकेरक्रिंडेमापलाभ कलेकलेठवडिठवड,

०

यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमु
ष्णम् ९ मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वा
मश्चायं नदति मधुरं चातकस्ते सगन्धः गर्भाधानक्षण
परिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे
भवन्तं बलाकाः १० तां चावश्यं दिवसगणनातत्परा
मेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम्
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यः पात
प्रणयि हृदयं विप्रयोगे रुणद्धि ११ कर्तुं यच्च प्र
भवति महीमुच्छिलीन्ध्रामवन्ध्यां तच्छ्रुत्वा ते श्रवणसुभगं
गर्जितं मानसोत्काः आकैलासाद्बिसकिसलयच्छेद
पाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सह
याः १२ मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् खिन्नः खि
न्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः प
रिलघु पयः स्रोतसां चोपभुज्य १३ अद्रेः शृङ्गं हरति

पवनः किंश्चिमिद्गुस्मापीठि [illegible] किडमकिडंमगुमिद्गुम

तठिः [illegible] मनिमुलाद्र [illegible] पः पं [illegible] गर्भा

यश्चियति [illegible] लजभावलेदान ॥ ७८ ॥ [illegible] याहुडिकर

उवश्च [illegible] भाद्रलीकगाद्रु [illegible] भायक्त

लभृ [illegible] मं [illegible] कांकाविभायछडे [illegible]

डमखिर्यणियहेम [illegible] ॥ ७५ ॥ [illegible] मामिडक

विला [illegible] ठिलुः [illegible] लायमदवडलि [illegible] ः [illegible] यमाः

मडः [illegible] यलामगठि [illegible] माक [illegible] मालंकिहि [illegible]

[illegible] रील ॥ ७९ ॥ [illegible] भामावथमामिडयर्न

[illegible] भमपरिगडंभावभा [illegible] ः

[illegible] भपदृ [illegible]

[illegible] ः [illegible] ॥ ८१ ॥ [illegible] भायमाः [illegible]

[illegible] लल [illegible] मिरमायह [illegible] मगाः

[illegible] ममयि [illegible] भाष्ठिंम [illegible] ः [illegible]

[illegible] यकरभदक ॥ ८३ ॥ [illegible] याडः पलिलडकलर्यु

322

[illegible]

[illegible]

[illegible] ३८ [illegible]

[illegible]

[illegible]

[illegible] ३५ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

ज्ञितिः कनकाम्बुसूनाकान्तिमिपरभूपालः श्रियुवल्लीमवल्ल ।
उर्वं याम्बुद्भ्रमरमित्रपूर्णमल्लीयाभयवर्णां मष्टस्थामः भाउव ।
कुपः सेवविभारपाल्गुः ८ श्रिङ्गउभिज्ञनाननवपुकु
ऊऊल्लिभऊउं उँयेम्भनमूउउरवाउिभूद्भवंवद्भ ओल्लः । रवां ।
मूक्षभूयल्लविषभविक्रपादविमील्लां ठजिक्कदेविवविर
मिष्टांकुउिभूक्तिगालेभू ९ उभ्रामिज्ञैवनगालमदैचामि
[illegible]उक्षिल्लभूमकभूउिदउरयउँयभांकायगाक्षः भजुः
[illegible]पनउल्लयिउंगानिलः मऊउिद्वंश्रिजः मँवी [illegible]
[illegible]उआमीरदाय १० गीयंदभुद [illegible] पिमंकेमर्रं ।
[illegible]यिकुउभूषभभऊल्लाः कल्लीस्त्रारकमुमा । दगु
[illegible]मरकिंगनुभा । थायमिह्नः मागक्कभूलाल्लायम
[illegible]भालभ । ११ अंमूामिकूउभपिमाव ।
[illegible]भिः कल्लमेपंकऊभरकिंथवउयवउउ
[illegible]नाल्लैः स्थागालदकेका [illegible]
[illegible]ामुइयभ [illegible]